NAME

Subject

BINDING BY

Rugh Nath Zadoo

Prop.

ZADOO SILMI PLASTIC WORKS

Ganpat-yar, SRINAGAR, Kashmir.

CC-0. Narinder Safaya Collection. Digitized by eGangotri

(x) Use of hoisting the machines and tackle including their attachments anchorage and supports shall conform to the follo[w]
conditions:—

(a) These shall be of good mechanical construction, sound material and adequate strength and free from patent de[fects]
be kept in good repair and in good working order.

(b) Every rope used in hoisting or lowering materials or as a means of suspension ... and free from patent defects.

... having a minimum area of 6′ × 5′ ...

(2) Every crane driver or ... tempora[ry la]trines and urinals for the ... of the labourers eac[h] incharge of any hoisting ... latrines and urinals being provided ... woman.

(3) In the case of ev... ho... number of bathing and washing places one unit for ev[ery] ... or as m... places shall be suitably screened.

2(a) All the huts shall have walls of sun-dried or burnt bricks laid in mud mortar or other suitable lo[cal material] ... Engineer-in-charge. In case of sun-dried bricks, the walls should be plastered with mud gobri on b[oth sides] ... plaster with mud gobri and shall be at least 6″ above the surrounding ground. The roofs shall be laid w[ith] ... be approved by the Engineer-in-charge and the contractor shall ensure that throughout the period of the[ir] ...

(b) The contractor(s) shall provide each hut proper ventilation.

(c) All doors, windows, and ventilators shall be provided with suitable eaves for security purposes.

(d) There shall be kept an open space of at least 8 yards between the rows of huts which may be reduce[d] ... site with the approval of the Engineer-in-charge, back to back construction will be allowed.

3. *Water Supply.*—The contractor(s) shall provide adequate supply of water for the use of labourers. The ... of pure and whole-some water per head per day for drinking purposes and 3 gallons of clean water p[er] ... purposes. Where piped water supply is available, supply shall be at stand posts, and where the supply is ... of metal or masonary, shall be provided. The contractor(s) shall also his/their own cost make arra[ngements] ... supply, to his/their labour camp from the existing rains wherever available and shall pay all fees and ...

4. The site selected for the camp shall be high ground, removed from jungle.

5. *Disposal of Excreta.*—The contractor(s) shall make necessary arrangements for the disposal of excreta ... tion which shall be according to the requirements laid down by the Local Health Authorities. If t[he] ... the contractor(s) shall make arrangements for the removal of the excreta through the *Municipa[l]* ... the number of labourer employed so that arrangements may be made by such Committee/autho[rity] ... charges on this account shall be borne by the Contractor and paid direct by him to the Municipality/aut[hority] ... sweeper for every 8 seats in case of dry system.

6. *Drainage.*—The contractor(s) shall provide efficient arrangements for draining away sullage water s...

7. The contractor(s) shall make necessary arrangements for keeping the camp area sufficiently lighted to ...

8. *Sanitation.*—The contractor(s) shall make arrangements for conservancy and sanitation in the labour ... Public Health and Medical Authorities.

... In every case in which by virtue of the provisions of section 12 sub-section (1) of the Workmen's Compensat[ion Act] ... [comp]ensation to a workman employed by the contractor, in execution of the works, Government will recover ... [comp]ensation so paid and without prejudice to the rights of the Government under section 12, sub-section (2) of ... [reco]ver such amount or any part thereof by deducting it from the security deposit or from any sum due by the G[overnment] ... [con]tract or otherwise, Government shall not be bound to contest any claim made against it under section 12 ... [wri]tten request of the contractor and upon his giving to Government full security for all cases for which Gov[ernment] ... [cont]esting such claim.

(1)

CC-0. Narinder Safaya Collection. Digitized by eGangotri

CC-0. Narinder Safaya Collection. Digitized by eGangotri

(x) Use of hoisting the machines and tackle including their attachments anchorage and supports shall conform to the follo[illegible] conditions:—

(a) These shall be of good mechanical construction, sound material and adequate strength and free from patent de[illegible] be kept in good repair and in good working order.

(b) Every rope used in hoisting or lowering materials or as a means of suspension [illegible] be durable quality and adeq[illegible] and free from patent defects.

CC-0. Narinder Safaya Collection. Digitized by eGangotri

(2) Every crane driver hiosting appliance operator shall be properly qualified and no person under an age of 21 yea[illegible] incharge of any hoist machine including any scaffold wrinch or give signals to the operator.

(3) In the case of every hoisting machine and of every chain ring hook shackle survel and pulley block used in hoistin[illegible] or as means of suspension the safe working load shall be ascertained by adequate means. Every hoisting machine referred to above shall be plainly marked with the safe working load. In case of a hoisting machine having a variable load, each safe working load of the conditions under which it is applicable shall be clearly indicated. No part o[illegible] or any gear referred to above in this paragraph shall be loaded beyond the safe working load except for the purpose [illegible]

(4) In case of departmental machines, the safe working load shall be notified by the Electrical Engineer-in-charge. As r[illegible] tors machines the contractors shall notify the safe working load of the machine to the Engineer-in-charge brings any machinery to site of work and get it verified by the Electrical Engineer concerned.

(xi) Motors, Gewing, Transmission, Electric wiring and other dangerous parts of hiosting appliances should be provided [illegible] safeguards, hoisting appliances should be provided with such means as will reduce to the minimum the risk of accidental [illegible] load, adequate precautions should be taken to reduce to the minimum the risk of any part of a suspended load b[illegible] dentally displaced. When workers employed on electrical installations which are already energised, insulating mats, we[illegible] such as gloves, sleeves and boths as may be necessary should be provided. The workers should not wear any rings carry keys or other materials which are good conductors of electricity.

(xii) All scaffolds, ladders and other safety devices mentioned or described herein shall be maintained in safe condition and ladder or equipment shall be altered or removed while it is in use. Adequate washing facilities should be provided at [illegible] of work.

(xiii) These safety provisions should be brought to the notice of all concerned by display on a notice board at a prominent place at The person responsible for compliance of the safety code shall be named therein by the contractor.

(xiv) To ensure effective enforcement of the rules and regulations relating to safety precautions, the arrangements made by t[illegible] shall be opened to inspection by the Labour Officer, Engineer-in-charge, of the department of their representatives.

(xv) Notwithstanding the above clauses from (i) to (xiv) there is nothing in these to exempt the contractor.


[illegible]B. The contractor shall submit by the 4th and 19th every month, to the Engineer-in-charge a true statement showing in respect of the [illegible] receding month and the first half of the current month, respectively, (1) the number of labourers employed by him on the work, (2) [illegible] (3) the wages paid to them (4) the accidents that occurred during the said fortnight showing the circumstances under which they happ[illegible] [illegible] of damage and injury caused by them and (5) the number of female workers who have been allowed Maternity Benefit according to clau[illegible] [illegible]t paid to them failing which the contractor shall be liable to pay to Government a sum not exceeding Rs. 50 for each default or mater[illegible] [illegible]ent. The decision of the Executive Engineer shall be final in deducting from any bill due to the contractor the amount levied as fine.

[illegible]C. In respect of all labour directly or indirectly employed in the works for the performance of the contractor's part or this agreement, [illegible]omply with or cause to be complied with all the rules framed by Government from time to time for the protection of health and sanitary a[illegible] [illegible]rs employed by the Central Public Works Department and its contractors.

[illegible]D. *Maternity benefit rules for female workers employed by Contractor.*—Leave and pay during leave shall be regulated as follows :—

1. LEAVE —(i) *In case of delivery.*—Maternity leave not exceeding 8 weeks ; 4 weeks upto and including the day of delivery following that day.

(1) (ii) *In case of miscarriage.*—Up to 8 weeks from the date of miscarriage.



CC-0. Narinder Safaya Collection. Digitized by eGangotri

CC-0. Narinder Safaya Collection. Digitized by eGangotri

श्रीः

॥ पञ्चस्तवी ॥

कतिपयसरलपदान्तरालङ्कृता
संस्कर्तृप्रणीतराज्ञीशारिकाज्वालास्तोत्रचतुष्टयान्विता
कक्षेत्युपाह्वपण्डितनाथरामशास्त्रिसंस्कृता ॥

पण्डितमाधवराम केशवरामाभ्यां
स्वीये
काश्मीरमार्कण्टायल प्रेस नाम्नि मुद्रणालये
मुद्रयित्वा प्रकाशिता ।

संवत् १९६५

दीपमालाङ्कः

॥=

CC-0. Narinder Safaya Collection. Digitized by eGangotri

CC-0. Narinder Safaya Collection. Digitized by eGangotri

ॐ

पञ्चस्तवी ।

लघुस्तवः प्रथमः ।

ॐ नमस्त्रिपुरसुन्दर्यै ।

[1]ऐन्द्र[2]स्येव शरासनस्य दधती मध्ये[3]ललाटं प्रभां ।
शौ[4]क्लीं कान्तिमनु[5]ष्णगोरिव शिरस्यातन्वती सर्वतः ॥
एषासौ त्रि[6]पुरा हृदि द्युतिरिवोष्णांशोः सदाहःस्थिता ।
छिन्द्यान्नः सहसा प[7]दैस्त्रिभिरघं ज्योतिर्मयी वाङ्मयी ॥ १ ॥

---

१ मंत्रोद्धारादिविधिरत्र दैशिकमुखादेवावगंतव्यः। २ इन्द्रसम्बन्धिनः। ३ अव्ययीभावः ४ शुक्लरूपाम्। ५ सोमस्य। ६ त्रिषु ललाटादिविशेषपुरेषु वर्तमाना चिद्दीप्तिः। ७ ललाटादिभिः स्थानैर्वर्णै[illegible]

CC-0. Narinder Safaya Collection. Digitized by eGangotri

या मात्रा त्र[1]पुसीलतातनुलसत्तन्तूत्थितिस्पर्धिनी ।
वाग्बीजे प्रथमे स्थिता तव सदा तां मन्महे ते वयम् ॥
शक्तिः कुण्डलिनीति विश्वजननव्यापारबद्धोद्यमा ।
ज्ञात्वेत्थं न पुनः स्[2]पृशन्ति जननीगर्भेऽर्भकत्वं नराः ॥ २ ॥
दृष्ट्वा संभ्र[3]मकारि वस्तु सहसा ऐ ऐ इति व्याहृतं ।
येनाकू[4]तवशादपीह वरदे बिन्दुं विनाप्यक्षरम् ॥
तस्यापि ध्रुवमेव देवि तरसा जाते तवानुग्रहे ।
वाचः सूक्तिसुधारसद्र[5]वमुचो निर्यान्ति वक्त्राम्बुजात् ॥ ३ ॥
यन्नित्ये ! तव कामराजमपरं मन्त्राक्षरं निष्क[6]लं ।

---

१ कर्कटलतायाः सूक्ष्माः प्रसरन्तश्च ये तंतवस्तेषां प्रथमारम्भमनुकरोतीति तथोक्ता ।
२ पुनर्नावर्तन्त इत्यर्थः । ३ त्रासविधायि सर्पादिकम् । ४ भयाद्यभिप्रायात् । ५ सारोद्धारः अमृतमाधुर्यमिवोद्गिरन्त्य इत्यर्थः । ६ कलातीतम् ।

CC-0. Narinder Safaya Collection. Digitized by eGangotri

तत्सा[1]रस्वतमित्यवैति विरलः कश्चिद्बुधश्चेद्भुवि ॥
आ[2]ख्यानं प्रतिप[3]र्व सत्य[4]तपसो यत्कीर्तयन्तो द्विजाः ।
प्रारम्भे प्रणवास्प[5]दप्रणयितां नीत्वोच्चरन्ति स्फुटम् ॥ ४ ॥
यत्सद्यो वचसां प्रवृत्तिकरणे दृष्टप्रभावं बुधैः ।
स्ता[6]र्तीयीकमहं नमामि मनसा त्वद्बीजमिन्दुप्रभम् ॥
अस्त्वौर्वोऽपि सर[7]स्वतीमनुगतो जाड्याम्बुविच्छित्तये ।
गोशब्दो गि[8]रि वर्तते स नियतं योगं विना सिद्धिदः ॥ ५ ॥
एकैकं तव देवि बीजमनघं सव्यञ्जनाव्यञ्जनं ।
कू[9]टस्थं यदि वा पृथक्क्रमगतं यद्वा स्थितं व्युत्क्र[10]मात् ॥

---

१ सरस्वतीदेवताकम् । २ या पश्यति न सा ब्रूते या ब्रूते सा न पश्यति । अहो व्याध स्वकार्यार्थी कं पृच्छसि मुहुर्मुहुरिति पद्यान्तर्गतमितिहासम् । ३ पूर्णिमादौ । ४ एतदाख्यस्य ब्रह्मर्षेः । ५ ओंकारस्थानसम्बन्धितां नीत्वा । ६ तृतीयम् । ७ एतदाख्यां नदीं च । ८ वाण्याम् ९ अनेकाक्षरसंयुक्तम् । १० विपरीतक्रमात् ।

CC-0. Narinder Safaya Collection. Digitized by eGangotri

यं यं काममपेक्ष्य येन विधिना केनापि वा चिन्तितं ।
जप्तं वा सफलीकरोति सहसा तं तं समस्तं नृणाम् ॥ ६ ॥
वामे[1] पुस्तकधारिणीमभयदां[2] साक्षस्रजं[3] दक्षिणे ।
भक्तेभ्यो वरदानपेशलकरां[4] कर्पूरकुन्दोज्ज्वलाम्[5] ॥
उज्जृम्भाम्बुजपत्रकान्तनयनस्निग्धप्रभालोकिनीं[6] ।
ये त्वामम्ब ! न शीलयन्ति[7] मनसा तेषां कवित्वं कुतः ॥ ७ ॥
ये त्वां पाण्डुरपुण्डरीकपटलस्पष्टाभिरामप्रभां[8] ।
सिञ्चन्तीममृतद्रवैरिव[9] शिरो ध्यायन्ति मूर्ध्नि स्थिताम् ॥
अश्रान्तं[10] विकटस्फुटाक्षरपदा[11] निर्याति वक्त्राम्बुजा- ।

१ द्वितीयवामकरे । २ जपमालाधारिणीम् । ३ द्वितीयदक्षिणकरे । ४ ललितहस्ताम् । ५ धवलाम् । ६ विकसितपद्मपत्रवत् शुक्लवर्णे ये नेत्रे तयोर्या विशेषरम्या स्नेहयुक्ता च प्रभा तयालोकते तच्छीलेति तथोक्ताम् । ७ आराधयन्ति । ८ सितवर्णामित्यर्थः । ९ रसैः । १० निरन्तरम् । ११ उदाराणि च प्रकटार्थानि अक्षराणि येषु एवंभूतानि पदानि यस्याः ।

CC-0. Narinder Safaya Collection. Digitized by eGangotri

तेषां भारति! भारती सु[1]रसरित्कल्लोलकोलोर्मिवत् ॥ ८ ॥
ये सिन्दूरप[2]रागपुञ्जपिहितां[3] त्वत्तेजसा द्यामिमा-।
मुर्वीं चापि विलीन[4]यावकरसप्रस्तारमग्नामिव ॥
पश्यन्ति क्षणमप्यनन्य[5]मनसस्तेषामनङ्ग[6]ज्वर-।
क्रान्तास्त्रस्तकुरङ्गशावकदृशो[7] वश्या भवन्ति स्फुटम् ॥ ९ ॥
चञ्चत्काञ्चनकुण्डलाङ्गदधरामाबद्धकाञ्चीस्रजं ।
ये त्वां चेतसि तद्गते क्षणमपि ध्यायन्ति कृत्वा स्थितिम् ॥
तेषां वेश्मसु विभ्रमादहरहः[9] स्फारीभवन्त्यश्चिरं ।
माद्यत्कुञ्जर[10]कर्णतालतरलाः स्थैर्यं भजन्ते श्रियः ॥ १० ॥

---

१ अखिन्नप्रसरत्वादित्यर्थः । २ धूलिः । ३ व्याप्ताम् । ४ गलदलक्तकद्रवाबिन्दुदंतुरामिव । ५ एकाग्रचित्ताः । ६ कन्दर्पार्तिपीडिताः । ७ मृगाद्यः स्त्रियः । ८ देदीप्यमानम् । ९ उत्तरोत्तरं वर्धमानाः । १० [illegible]

CC-0. Narinder Sefaya Collection. Digitized by eGangotri

आ[1]र्भट्या शशिखण्डमण्डितजटाजूटां नृमुण्ड[2]स्रजं ।
बन्धूक[3]प्रसवारुणाम्बरधरां प्रेतासनाध्यासिनीम् ॥
त्वां ध्यायन्ति चतुर्भुजां त्रिनयनामापीनतुङ्गस्तनीं ।
मध्ये निम्नवलित्रयांकिततनुं त्वद्रूपसंवित्तये ॥ ११ ॥
जातोऽप्यल्पप[4]रिच्छदे क्षितिभुजां स[5]मान्यमात्रे कुले ।
निःशेषावनिचक्रवर्तिपदवीं लब्ध्वा प्रतापोन्नतः ॥
यद्विद्याधरवृन्दवन्दितपदः श्रीवत्सराजोऽभव- ।
देवि ! त्वच्चरणाम्बुजप्रणतिजः सोयं प्रसादोदयः ॥ १
चण्डि त्वच्चरणाम्बुजार्चनविधौ बि[6]ल्वीदलोल्लुण्ठन- ।

---

१ या तु प्रौढार्थसंदर्भवृत्तिरारभटी तु सेति लक्षितया वीररसाश्रययोद्धतया वृत्त्या
२ कपालमालाधारिणीम् । ३ जपापुष्पम् । ४ अल्पपरिवारे । ५ अनुत्कृष्टे । ६
[illegible]पत्रैः ।

CC-0. Narinder Salaya Collection. Digitized by eGangotri

त्रुट्यत्कण्टककोटिभिः परि¹चयं येषां न जग्मुः कराः ॥
ते दण्डांकुशचक्रचापकुलिशश्रीवत्समत्स्यांकितै- ।
र्जायन्ते पृथिवीभुजः कथमिवाम्भोजप्रभैः पाणिभिः ॥१३॥
विप्राः क्षो²णिभुजो विशस्तदि³तरे क्षीराज्यमध्वासवै- ।
स्त्वां देवि ! त्रिपुरे ! परापरमयीं सन्तर्प्य पूजाविधौ ॥
यां यां प्रार्थयते म⁴नः स्थि⁵रधियां तेषां त⁶ एव ध्रुवं ।
तां तां सिद्धिमवाप्नुवन्ति तरसा विघ्नैरविघ्नीकृताः ॥ १४ ॥
शब्दानां जननी त्वमत्र भुवने वाग्वादिनीत्युच्यसे ।
त्वत्तः केशववासवप्रभृतयोऽप्याविर्भवन्ति स्फुटम् ॥
लीयन्ते खलु यत्र क⁷ल्पविरमे ब्रह्मादयस्तेऽप्यमी ।

---

१ संपर्कम् । २ क्षत्रियाः । [illegible] पदमेतत् । [illegible] ब्रह्मादयः
७ कल्पान्ते ।

CC-0. Narinder Safaya Collection. Digitized by eGangotri

सा त्वं काचिदचिन्त्यरूपमहिमा शक्तिः परा गीयसे ॥१५॥
देवानां त्रितयं त्रयी[1] हुतभुजां शक्तित्रयं[2] त्रिस्वरा-[3] ।
स्त्रैलोक्यं त्रिपदी[4] त्रिपुष्करमथो[5] त्रिब्रह्म[6] वर्णास्त्रयः[7] ॥
यत्किञ्चिज्जगति त्रिधा नियमितं वस्तु त्रिवर्गात्मकं[8] ।
तत्सर्वं त्रिपुरेति[9] नाम भगवत्यन्वेति ते तत्त्वतः ॥ १६ ॥
लक्ष्मीं राजकुले जयां रणभुवि क्षेमंकरीमध्वनि ।
क्रव्यादद्विपसर्पभाजि शबरीं कान्तारदुर्गे[10] गिरौ ॥
भूतप्रेतपिशाचजम्बुकभये स्मृत्वा महाभैरवीं ।
व्यामोहे[11] त्रिपुरां तरन्ति विपदस्तारां च तोयप्लवे[12] ॥ १७ ॥

---

१ दक्षिणाग्निगार्हपत्याहवनीयरूपा । २ इच्छादि ब्राह्मयादि वा । ३ उदात्तादयः । ४ गायत्र्याः पदत्रयम् । हृदादि वा । ५ गंगायमुनासरस्वतीति जलत्रयी । ६ वेदत्रयी । ७ अकारोकारमकाररूपाः । ८ धर्मार्थकामात्मकम् । ९ जाग्रदाद्यवस्थात्रयव्यापिमती चिद्रूपा शक्तिः ।
१० दु[illegible]

CC-0. Narinder Safaya Collection. Digitized by eGangotri

माया कुण्डलिनी क्रिया मधुमती काली कला[1] मालिनी ।
मातङ्गी विजया जया भगवती[2] देवी शिवा शाम्भवी ॥
शक्तिः शङ्करवल्लभा त्रिनयना वाग्वादिनी भैरवी[3] ।
ह्रींकारी त्रिपुरा परापरमयी[4] माता[5] कुमारी[6]त्यसि ॥ १८ ॥
आई[7]पल्लवितैः परस्परयुतैर्द्वित्रिक्रमाद्यक्षरैः ।
काद्यैः क्षान्तगतैः स्वरादिभिरथ क्षान्तैश्च तैः सस्वरैः ।
नमानि त्रिपुरे ! भवन्ति खलु यान्यत्यन्तगुह्यानि ते ।
तेभ्यो भैरवपत्नि ! विंशतिसहस्रेभ्यः परेभ्यो नमः ॥ १९ ॥
बोद्धव्या निपुणं बुधैः स्तुतिरियं कृत्वा मनस्तद्गतं ।

---

१ किंचित्कर्तृत्वरूपिणी । २ ऐश्वर्यादिषट्कवती । ३ भरणाद्रवणाद्वमनाद्वा । ४ सूक्ष्मस्थूलमयी । ५ उत्पत्तिकारिणी । ६ [illegible] ७ [illegible] ८ [illegible]नि ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

भारत्या त्रिपुरेत्यनन्य[1]मनसा यत्राद्य[2]वृत्ते स्फुटम् ॥
एकद्वित्रिपदक्रमेण कथितस्त्वत्पादसंख्याक्षरै- ।
र्मन्त्रोद्धारविधिर्विशेष[3]सहितः सत्संप्रदाया[4]न्वितः ॥ २० ॥
सावद्यं[5] निरवद्यमस्तु यदि वा किंवानया चिन्तया ।
नूनं स्तोत्रमिदं पठिष्यति नरो यस्यास्ति भक्तिस्त्वयि ।
संचिन्त्यापि लघुत्वमात्मनि दृढं संजायमानं हठा- ।
त्त्वद्भक्त्या मुखरीकृ[6]तेन रचितं यस्मान्मयापि ध्रुवम् ॥ २१ ॥

इति श्रीपञ्चस्तव्यां लघुस्तवः ।

---

१ तद्गतमनसाः । २ प्रथमे श्लोके । ३ सव्यंजनत्वादिविशेषसहितः । ४ अविच्छिन्नाचार्योपदेशेनानुगतः । ५ सदोषम् । ६ उत्साहितेन ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

चर्चास्तवो द्वितीयः

ॐनमस्त्रिपुरसुन्दर्यै ।

ॐ आनन्दसुन्दरपुरन्दरमुक्तमाल्यं ।
मौलौ हठेन [1]निहितं महिषासुरस्य ॥
पादाम्बुजं भवतु मे विजयाय [2]मञ्जु ।
[3]मञ्जीरशिञ्जितमनोहरमम्बिकायाः ॥ १ ॥
सौन्दर्य[4]विभ्रमभुवो भुवनाधिपत्य- ।
सम्पत्तिकल्पतरवस्त्रिपुरे जयन्ति ॥
एते कवित्वकुमुद[5]प्रकरावबोध[6]- ।

---

१ स्थापितम् । २ सुन्दरम् । ३ नूपुरशब्दमनोहरम् । ४ विलासोत्पत्तिहेतवः । ५ षण्डं समूह इत्यर्थः । ६ विकासः ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

पूर्णेन्दवस्त्वयि जगज्जननि प्रणामाः ॥ २ ॥

देवि ! स्तुतिव्यतिकरे[1] कृतबुद्धयस्ते[2] ।
वाचस्पतिप्रभृतयोऽपि जडीभवन्ति[3] ॥
तस्मान्निसर्गजडिमा कतमोऽहमत्र ।
स्तोत्रं तव त्रिपुरतापनपत्नि कर्तुम् ॥ ३ ॥

मातस्तथापि भवतीं भवतीव्रताप- ।
विच्छित्तये[4] स्तुतिमहार्णवकर्णधारः[5] ॥
स्तोतुं भवानि ! स भवच्चरणारविन्द-
भक्तिग्रहः[6] किमपि मां मुखरीकरोति[7] ॥ ४ ॥

---

१ संपर्के । २ बुद्धिकौशलयुक्ताः । ३ त्वन्महिम्नोऽगणनीयत्वात् । ४ नाशाय । ५ तारकः । ६ निरतिशयानुरागः । ७ अबद्धमुखं करोति ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

सूते[1] जगन्ति भवती[2] भवती[3] बिभर्ति[4] ।
जागर्ति[5] तत्त्वयकृते भवती[6] भवानि ! ॥
मोहं[7] भिनत्ति भवती[8] भवती[9] रुणद्धि[10] ।
लीलायितं[11] जयति चित्रमिदं भवत्याः ॥ ५ ॥

यस्मिन्मनागपि नवाम्बुजपत्रगौरि ! ।
गौरि ! प्रसादमधुरां दृशमादधासि ॥
तस्मिन्निरन्तरमनङ्ग[12]शरप्रकीर्णाः ।
सीमन्तिनीनयनसंततयः पतन्ति ॥ ६ ॥

---

१ सृजति । २ ब्राह्मीरूपा । ३ वैष्णवीरूपा । ४ पुष्णाति । ५ सततोद्युक्ता भवति । ६ रौद्रीरूपा । ७ अख्यातिम् । ८ ईश्वररूपा । ९ सदाशिवरूपा । १० स्वरूपं पिधत्ते । ११ लीलैवैषेत्यर्थः । १२ संमोहनादिभिर्विक्षिप्तीकृता याः स्त्रियस्तासां दृष्टयः ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

पृथ्वीभुजोऽप्युदयनप्रवरस्य तस्य ।
विद्याधरप्रणतिचुम्बितपादपीठः ॥
यच्चक्रवर्तिपदवीप्रणयः[1] स एष ।
त्वत्पादपङ्कजरजःकणजः प्रसादः ॥ ७ ॥

त्वत्पादपङ्कजरजःप्रणिपातपूतैः ।
पुण्यैरनल्पमतिभिः कृतिभिः कवीन्द्रैः ॥
क्षीर[2]क्षपाकरदुकूलहिमावदाता ।
कैर[3]प्यवा[4]पि भुवनत्रितयेऽपि कीर्तिः ॥ ८ ॥

कल्पद्रुमप्रसवकल्पितचित्रपूजा- ।
मुद्दीपित[5]प्रियतमामदरक्तगीतिम् ॥

१ चक्रवर्तित्वप्राप्तिः । २ शुक्लवर्णा । ३ अनिर्वचनीयमहिमशालिभिः । ४ प्राप्ता । ५ उद्दीपिता द्योतिताऽतिप्रिया मदेन रक्ता च गीतिर्यस्यास्तां तथोक्ताम् ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

नित्यं भवानि ! भवतीमुपवीणयन्ति[1] ।
विद्याधराः कनकशैल[2]गुहागृहेषु ॥ ९ ॥
लक्ष्मीवशीकरणकर्मणि कामिनीना-
माकर्षणव्यतिकरेषु[3] च सिद्धमन्त्रः ॥
नीरन्ध्रमोहतिमिरच्छिदुरप्रदीपो[4] ।
देवि ! त्वदंघ्रिजनितो जयति प्रसादः ॥ १० ॥
देवि ! त्वदंघ्रिनखरत्नभुवो मयूखाः ।
प्रत्यग्र[5]मौक्तिकरुचो मुदमुद्वहन्ति[6] ॥
सेवाञ्जलिव्यतिकरे[7] सुरसुन्दरीणां ।

१ वीणयोपगायन्ति । २ सुमेरुः । ३ वशीकरणसंयोगेषु । ४ गाढमोहान्धकारनाशकः । ५ नूतनम् । ६ आवहन्ति । ७ सेवायां प्रणामकरणे ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

सीमन्तसीम्नि[1] कुसुमस्तवकायितं[2] यैः ॥ ११ ॥

मूर्ध्नि स्फुरत्[3]तुहिनदीधितिदीप्तिदीप्तं ।

मध्ये ललाट[4]ममरायुधरश्मिचित्रम्[5] ॥

हृच्चक्र[6]चुम्बि हुतभुक्कणिका[7]नुरूपं ।

ज्योतिर्यदेतदिदमम्ब ! तव स्वरूपम् ॥ १२ ॥

सिन्दूरपांसुपटलच्छुरितामिव द्यां ।

त्वत्तेजसा जतुरसस्नपितामिवोर्वीम् ॥

यः पश्यति क्षणमपि त्रिपुरे विहाय ।

व्रीडां[9] मृडानि ! सुहृशस्तमनुद्रवन्ति ॥ १३ ॥

मातर्मुहूर्तमपि यः स्मरति स्वरूपं ।

---

१ केशरचनामर्यादायाम् । २ पुष्पस्तब्रकवदाचरितम् । ३ चन्द्रवर्णाम् । ४ अव्ययीभावः ।
५ [illegible] । ६ [illegible] । ७ [illegible] । ८ [illegible] । ९ लज्जाम् ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

लाक्षारसप्रसरतन्तुनिभं भवत्याः ॥
ध्यायन्त्यनन्यमनसस्तमनङ्गतप्ताः ।
प्रद्युम्नसीम्नि सुभगत्वगुणं[1] तरुण्यः ॥ १४ ॥
आधारमारुतनिरोधवशेन[2] येषां ।
सिन्दूररञ्जितसरोजगुणानुकारि[3] ॥
तीव्रं हृदि स्फुरति देवि ! वपुस्त्वदीयं ।
ध्यायन्ति तानिह समीहितसिद्धसाध्याः[4] ॥ १५ ॥
ये चिन्तयन्त्यरुणमण्डलमध्यवर्ति ।
रूपं तवाम्ब ! नवयावकपंकपिंगम्[5] ॥

---

१ सौभाग्ययुक्तम् । २ मूलाधारप्राणशक्तिनिरोधतः । ३ पद्मतंतुसदृशम् । ४ सिद्धाभिलाषिताः साध्याख्या देवाः । ५ लाक्षारसः ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

तेषां सदैव कुसुमायुधबाणभिन्न- ।
वक्षःस्थला मृगदृशो वशगा भवन्ति ॥ १६ ॥

रूपं तव स्फुरितचंद्रमरीचिगौर- ।
मालोकते मनसि वागधिदैवतं यः ॥
निस्सीमसूक्तिरचनामृतनिर्झरस्य[1] ।
तस्य प्रसादमधुराः[2] प्रसरन्ति वाचः ॥ १७ ॥

शर्वाणि ! सर्वजनवन्दितपादपद्मे ! ।
पद्मच्छदच्छविविडम्बितनेत्रलक्ष्मि[3] ॥
निष्पापमूर्तिजनमानसराजहंसि[4] ! ।

---

१ निरवधि यत् शोभनोक्तिरचनारूपममृतं तस्य निर्झरः प्रवाहः प्रसरो अखिन्नत्वा तस्य । २ प्रसादगुणलालिताः । ३ पद्मपत्रशोभयाऽनुकृतनेत्रकान्ते । ४ मनः सरश्च ।

CC-0. Narinder Safaya Collection. Digitized by eGangotri

हंसि[1] त्वमापदमनेकविधां जनस्य ॥ १८ ॥
इच्छानुरूपमनुरूप[2]गुणप्रकर्षं ।
साङ्कर्षणि[3] त्वमनुसृत्य यदा बिभर्षि ॥
जायेत स त्रिभुवनैकगुरुस्तदानीं ।
देवः शिवोऽपि भुवनत्रयसूत्रधारः[4] ॥ १९ ॥
योऽयं चकास्ति गगनार्णवरत्नमिन्दु- ।
योऽयं सुरासुरगुरुः पुरुषः[5] पुराणः ॥
यद्धाममर्धमिदमन्धकसूदनस्य[6] ।
देवि ! त्वमेव तदिति प्रतिपादयन्ति[7] ॥ २० ॥

---

१ अपाकरोषि । २ सदृशम् । ३ हे कालाग्निरुद्रशक्ते । ४ नाटकाचार्यः । ५ नारायणः । ६ शिवस्य । ७ अंगीकुर्वन्ति ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

ध्यातासि हैमवति[१] येन हिमांशुरश्मि[२]- ।
मालाऽमलद्युतिरकल्मष[३]मानसेन ॥
तस्याऽविलम्बमनवद्य[४]मनन्त[५]कल्प- ।
मल्पैर्दिनैः सृजसि सुन्दरि वाग्विलासम्[६] ॥ २१ ॥

त्वां व्यापिनीति सुमना इति कुण्डलीति ।
त्वां कामिनीति कमलेति कलावतीति ॥
त्वां मालिनीति ललितेत्यपराजितेति ।
देवि ! स्तुवन्ति विजयेति जयेत्युमेति ॥ २२ ॥

उद्दाम[७]कामपरमार्थ[८]सरोजषण्ड- ।

---

१ पार्वति । २ शुक्लरूपा । ३ शुद्धान्तःकरणेन । ४ निर्दोषम् । ५ प्रभूततरम् । ६ वाङ्मा[illegible]
७ [illegible] कमलवन्दविकासे सूर्यदीप्तिम्

CC-0. Narinder Safaya Collection. Digitized by eGangotri

चण्डद्युतिद्युतिमुपासितषट्प्रकाराम्[1] ॥

मोहद्विपेन्द्रकदनोद्यतबोधसिंह-[2][3] ।

लीलागुहां[4] भगवतीं त्रिपुरां नमामि ॥ २३ ॥

गणेशवटुकस्तुता[5] रतिसहायकामान्विता[6] ।

स्मरारिवराविष्टरा कुसुमबाणबाणैर्युता[7] ॥

अनंगकुसुमादिभिः परिवृता च सिद्धैस्त्रिभिः[8] ।

कदम्बवनमध्यगा त्रिपुरसुन्दरी पातु नः ॥ २४ ॥

त्वामैन्दवीमिव[9] कलामनुभालदेश- ।

---

१ अङ्गीकृतषट्चक्रादिविशेषाम् । षट्चक्रप्रकारत उपासितां वा । २ विनाशः । ३ ज्ञानम् । ४ क्रीडावासस्थितिम् । ५ मायया वटुभूतो वामनावतारः को ब्रह्मा । ६ रतिप्रीत्यादिभिः स्वशक्तिभिः सहितैरेकोनपंचाशन्मिथुनरूपकामकामदादिभिरन्विता । ७ अष्टभिर्गुरुतरयोगिनीभिः । ८ दिव्यौघसिद्धौघमानवौघरूपैः । ९ चान्द्रीम् ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

मुद्भासिताम्बरतलामवलोकयन्तः ॥
सद्यो भवानि ! सुधियः कवयो भवन्ति ।
त्वं [1]भावनाहितधियां [2]कुलकामधेनुः ॥ २५ ॥

उत्तप्तहेमरुचिरे त्रिपुरे ! पुनीहि ।
चेतश्चिरन्तनमघौघवनं लुनीहि ॥
कारागृहे नि[3]गडबन्धनपीडितस्य ।
त्वत्संस्मृतौ झटिति मे निगडास्त्रुटन्ति ॥ २६ ॥

रुद्राणि विद्रुममयीं प्रतिमामिव त्वां ।
ये चिन्तयन्त्यरुणकान्तिमनन्यरूपाम् ॥
तानेत्य पद्मलदृशः प्रस[5]भं भजन्ते ।

---

१ ध्यानस्थितबुद्धीनाम् । २ सर्वप्रदेत्यर्थः । ३ शृङ्खला । ४ हे रुद्रशक्ते । ५ हठात् ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

कण्ठ[1]ावसक्तमृदुबाहुलतास्तरुण्यः ॥ २७ ॥

त्वद्रूपमुल्ल[2]सितदाडिमपुष्परक्त- ।

मुद्भाव[3]येन्मदनदैवतमक्षरं यः ॥

तं रूपहीनमपि मन्मथनिर्विशेष[4]- ।

मालोकयन्त्युरुनितम्बभरास्तरुण्यः ॥ २८ ॥

त्वद्रूपैकनि[5]रूपणप्रणयिताबन्धो दृशोस्त्वद्गुण- ।

[6]ग्रामाकर्णनरागिता श्रवणयोस्त्वत्संस्मृतिश्चेतसि

त्वत्पादार्चनचा[7]तुरी करयुगे त्वत्कीर्तनं वाचि मे ।

कुत्रापि त्वदुपासनव्यस[8]निता मे देवि ! मा शाम्यतु ।२९

---

१ कंठे आलिङ्गनार्थं स्थापिताः । २ विकसितम् । ३ ध्यायेत् । ४ कामसदृशमित्यर्थः ।
५ निश्चयकरणे सचेष्टता । ६ समूहः । ७ चातुर्यम् । ८ तत्परता मम इत्यर्थः ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

य: स्तोत्रमेतदनुवासरमीश्वराया: ।
श्रेयस्करं पठति वा यदि वा शृणोति ॥
तस्येप्सितं फलति राजभिरीड्यतेऽसौ ।
जायेत स प्रियतमो हरिणेक्षणानाम् ॥ ३० ॥

ब्रह्मेन्द्ररुद्रहरिचन्द्रसहस्ररश्मि-
स्कन्दद्विपाननहुताशनवन्दितायै ॥
वागीश्वरि ! त्रिभुवनेश्वरि ! विश्वमात-
रन्तर्बहिश्च कृतसंस्थितये नमस्ते ॥ ३१ ॥

इति श्रीपञ्चस्तव्यां चर्चास्तवो द्वितीयः

—0—

१ प्रतिदिनम् ।

CC-0. Narinder Safaya Collection. Digitized by eGangotri

घटस्तवस्तृतीयः ।

देवि! त्र्यम्बकपत्नि! पार्वति! सति! त्रैलोक्यमातः! शिवे! ।
शर्वाणि! त्रिपुरे! मृडानि! वरदे! रुद्राणि! कात्यायनि! ॥
भीमे! भैरवि! चण्डि! शर्वरि! कले! कालक्षये! शूलिनि! ।
त्वत्पादप्रणताननन्य[1]मनसः पर्याकुलान्पाहि नः ॥ १ ॥

उन्मत्ता इव स[2]ग्रहा इव विषव्यास[3]क्तमूर्च्छा इव ।
प्राप्तप्रौढमदा इवातिविरहग्रस्ता इवार्ता इव ॥
ये ध्यायन्ति हि शैलराजतनयां धन्यास्त एकाग्रत- ।
स्त्यक्तोपाधिविवृद्धरागमनसो ध्यायन्ति वामभ्रुवः ॥ २ ॥

---

१ त्वदेकाग्रमनसः । २ भूताद्याविष्टा इव । ३ उत्पन्नमोहाः ।

CC-0. Narinder Safaya Collection. Digitized by eGangotri

देवि ! त्वां सकृदेव यः प्रणमति क्षोणीभृतस्तं नम- ।
न्त्याजन्म स्फुरदंघ्रिपीठविलुठत्कोटीरकोटिच्छटाः ॥
यस्त्वामर्चति सोऽर्च्यते सुरगणैर्यः स्तौति स स्तूयते ।
यस्त्वां ध्यायति तं स्मरार्तिविधुरा ध्यायन्ति वामभ्रुवः ॥३

ध्यायन्ति ये क्षणमपि त्रिपुरे ! हृदि त्वां ।
लावण्ययौवनधनैरपि विप्रयुक्ताः ॥
ते विस्फुरन्ति ललितायतलोचनानां ।
चित्तैकभित्तिलिखितप्रतिमाः पुमांसः ॥ ४ ॥

---

१ एकवारमेव । २ राजानः । ३ लग्नमुकुटाग्रप्रान्ताः । ४ कामपीडाविह्वलाः । ५ सु...
...यः । ६ विरहिताः । ७ रमन्त इत्यर्थः । ८ चित्तरूपे चित्राश्रये लिखितमूर्तयः । ...
...विलासिनीभिर्ध्याता इत्यर्थः ।

CC-0. Narinder Safaya Collection. Digitized by eGangotri

एतं किं नु दृशा पिबाम्युत विशाम्यस्याङ्गमङ्गैर्निजैः ।
किं वाऽमुं निगलाम्यनेन सहसा किं वैकतामाश्रये ॥
तस्येत्थं विवशो[१] विकल्पघटनाकूतेन[२] योषिज्जनः ।
किं तद्यन्न करोति देवि! हृदये यस्य त्वमावर्तसे[३] ॥ ५ ॥
विश्वव्यापिनि! यद्वदीश्वर इति स्थाणावनन्याश्रयः ।
शब्दः शक्तिरिति त्रिलोकजननि! त्वय्येव तथ्यस्थितिः[४] ॥
इत्थं सत्यपि शक्नुवन्ति यदिमाः क्षुद्रा रुजो बाधितुं ।
त्वद्भक्तानपि न क्षिणोषि च रुषा तद्देवि! चित्रं महत् ॥ ६ ॥
इन्दोर्मध्यगतां मृगाङ्कसदृशच्छायां मनोहारिणीं ।

---

१ पराधीनः । २ कथं कथं तेन सह रमे इति संकल्पविशेषाभिप्रायेण । ३ पुनः पुनः स्फुरसि । ४ सत्यप्रतिष्ठः । ५ ता रुजः ।

CC-0. Narinder Safaya Collection. Digitized by eGangotri

पाण्डूत्फुल्लसरोरुहासनगतां स्निग्धप्रदीपच्छविम् ॥
वर्षन्तीममृतं भवानि ! भवतीं ध्यायन्ति ये देहिन-
स्ते निर्मुक्तरुजो भवन्ति विपदः प्रोज्झन्ति तान्दूरतः ॥ ७ ॥
पूर्णेन्दोः शकलैरिवातिबहलैः पीयूषपूरैरिव ।
क्षीराब्धेः लहरीभरैरिव सुधापङ्कस्य पिण्डैरिव ।
प्रालेयैरिव निर्मितं तव वपुर्ध्यायन्ति ये श्रद्धया ।
चित्तान्तर्निहतार्तितापविपदस्ते सत्पदं बिभ्रति ॥ ८ ॥
ये संस्मरन्ति तरलां सहसोल्लसन्तीं ।
त्वां ग्रन्थिपञ्चकभिदं तरुणार्कशोणाम् ।

---

१ सतैलः । २ अमृतप्रवाहैः । ३ मूलाधारादुद्यन्तीम् । ४ स्वाधिष्ठानादिचक्रपंचकम् । अविद्यास्मितारागद्वेषाभिनिवेशाख्यं क्लेशपंचकं वा ।

CC-0. Narinder Safaya Collection. Digitized by eGangotri

रागार्णवे बहलरागिणि मज्जयन्तीं[1] ।
कृत्स्नं जगद्दधति चेतसि तान्मृगाद्यः ॥ ९ ॥

लाक्षारसस्नपितपंकजतंतुतन्वी- ।
मन्तः स्मरत्यनुदिनं भवतीं भवानि ! ॥

यस्त्वं स्मरप्रतिममप्रतिमस्वरूपा[3] ।
नेत्रोत्पलैर्मृगदृशो भृशमर्चयन्ति[2] ॥ १० ॥

स्तुमस्त्वमां वाचमव्यक्तां[4] हिमकुन्देन्दुरोचिषम् ।
कदम्बमालां बिभ्राणामापादतललम्बिनीम् ॥ ११ ॥

मूर्ध्नीन्दोः सितपङ्कजासनगतां प्रालेयपाण्डुत्विषं ।

---

१ तन्मयीकुर्वतीम् । २ धारयन्ति । ३ अत्युत्तमस्वरूपाः । ४ परारूपाम् ।

CC-0. Narinder Safaya Collection. Digitized by eGangotri

वर्षन्तीममृतं सरोरुहभुवो वक्त्रे[1]ऽपि रंध्रे[2]ऽपि च ॥
अच्छिन्ना[3] च मनोहरा[4] च ललिता[5] चातिप्रसन्ना[6]पि च ।
त्वामेव स्मरतां स्मरारिदयिते! वाक्सर्वतो वल्गति[7] ॥ १२ ॥

ददातीष्टान्भोगान् क्षपयति रिपून् हन्ति विपदो ।
दहत्याधीन्[8]व्याधीञ् शमयति सुखानि प्रतनुते ॥
हठादन्तर्दुःखं दलयति पिनष्टीष्टविरहं ।
सकृद् ध्याता देवी किमिव निरवद्यं न कुरुते ॥ १३ ॥

यस्त्वां ध्यायति वेत्ति विन्दति जपत्यालोकते चिन्तय- ।
त्यन्वेति[9] प्रतिपद्यते[10] कलयति[11] स्तौत्याश्रयत्यर्चति[12] ॥

---

१ मूलाधारेऽपि । २ ब्रह्मरन्ध्रेऽपि । ३ ध्वनिगर्भत्वेनानर्गला । ४ निर्दोषत्वेन । ५ सालंकारत्वेन । ६ प्रसादादिगुणयुक्तत्वेन च । ७ अनवच्छिन्नत्वेन प्रसरति । ८ मानसीर्व्यथाः । ९ सेवकवदनुगच्छति । १० तांस्तान्नियमानङ्गीकरोति । ११ विचारयति । १२ शरण्यत्वेन ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

यश्च त्र्यम्बकवल्लभे ! तव गुणानाकर्णयत्यादरा- ।
त्तस्य श्रीर्न गृहाद्[1]पैति विजयस्तस्याग्रतो धावति ॥ १४ ॥
किं किं दुःखं दनुजदलिनि ! क्षीयते न स्मृतायां ।
का का कीर्तिः कुल[2]कमलिनि ! ख्या[3]प्यते न स्तुतायाम् ॥
का का सिद्धिः सुरवरनुते ! प्राप्यते नार्चितायां ।
कं कं योगं त्वयि न चि[4]नुते चित्तमाल[5]म्बितायाम् ॥१५॥
ये देवि ! दुं[6]र्धरकृतान्तमुखान्तरस्था ।
ये कालि ! कालघनपाशनितान्तबद्धाः ॥
ये चण्डि ! चण्[7]डगुरुकल्मषसिन्धुमग्ना- ।

---

१ अपगच्छति । २ षट्चक्रपद्मिनि । ३ विश्रूयते । ४ अधिगच्छति । ५ प्रापितायाम्
६ दुःसहः । ७ दुर्धर्षदुरन्तपापसागरब्रुडिताः ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

स्तान्पासि मोचयसि तारयसि स्मृतैव ॥ १६ ॥

लक्ष्मीवशीकरणचूर्णसहोदराणि[1] ।

त्वत्पादपंकजरजांसि चिरं जयन्ति ॥

यानि प्रणाममिलितानि नृणां ललाटे ।

लुम्पन्ति[2] दैवलिखितानि दुरक्षराणि[3] ॥ १७ ॥

रे[4] मूढाः! किमयं वृथैव तपसा देहः परिक्लिश्यते ।

यज्ञैर्वा बहुदक्षिणैः किमितरे रिक्तीक्रियंते[5] गृहाः ॥

भक्तिश्चेदविनाशिनी भगवतीपादद्वयी सेव्यता- ।

मुन्निद्राम्बुरुहातपत्रसुभगा[6] लक्ष्मीः पुरो धावति ॥१८॥

---

१ सदृशानि । २ परिमार्जयन्ति । ३ दौर्भाग्यसूचकानि अक्षराणि । ४ नीचसंबोधनम् ५ शून्यीक्रियन्ते . ६ उत्फुल्लम् ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

याचे न कंचन न कंचन वंचयामि ।
सेवे न कंचन निरस्तसमस्तदैन्यः ॥
श्लक्ष्णं[1] वसे[2] मधुरमद्मि भजे वरस्त्रीं ।
देवी हृदि स्फुरति मे कुलकामधेनुः[3] ॥ १९ ॥

शब्दब्रह्ममयि[4] स्वच्छे देवि त्रिपुरसुन्दरि ।
यथाशक्ति जपं पूजां गृहाण परमेश्वरि ॥ २० ॥

नन्दन्तु साधकाः सर्वे विनश्यन्तु विदूषकाः[5] ॥
अवस्था शाम्भवी मेऽस्तु प्रसन्नोऽस्तु गुरुः सदा ॥ २१ ॥

दर्शनात्पापशमनी जपान्मृत्युविनाशिनी ॥
पूजिता दुःखदौर्भाग्यहरा त्रिपुरसुन्दरी ॥ २२ ॥

---

१ कोमलम् । २ परिदधामि । ३ सुरभिवदखिलकामदा । ४ अनाहतध्वनिमयि । ५ निन्दका

CC-0. Narinder Safaya Collection. Digitized by eGangotri

नमामि यामिनीनाथलेखालंकृतकुन्तलाम् ॥
भवानीं भवसन्तापनिर्वापणसुधानदीम् ॥ २३ ॥
मंत्रहीनं क्रियाहीनं विधिहीनं च यद्गतम् ॥
त्वया तत्क्षम्यतां देवि कृपया परमेश्वरि ॥ २४ ॥

इति श्रीपंचस्तव्यां घटस्तवस्तृतीयः समाप्तः ।

---

१ चन्द्रलेखाशोभितालकाम् । २ संसारसंतापशान्तौ । अमृतनदीम् ।

CC-0. Narinder Safaya Collection. Digitized by eGangotri

अम्बास्तवश्चतुर्थः ।

ॐ यामाम[1]नन्ति मुनयः प्र[2]कृतिं पुराणीं ।
विद्येति यां श्रुतिरहस्यविदो वदन्ति ॥
तां[3]मर्धपल्लवितशङ्कररूपमुद्रां ।
देवीमनन्यशरणः शरणं प्र[4]पद्ये ॥ १ ॥

अम्ब स्तवेषु तव ता[5]वदकर्तृकाणि* ।
कुण्ठीभवन्ति वचसामपि गुम्फ[6]नानि ॥
डिम्भ[7]स्य मे स्तुतिरसावसम[8]ञ्जसापि ।
वात्सल्यनि[9]घ्नहृदयां भवतीं [10]धिनोति ॥ २ ॥

---

१ प्रतिपादयन्ति । २ जगद्योनिं । ३ अर्धे प्रकटिता शंकररूपस्याकृतिर्यया । ४ व्रजामि । ५ साकल्येन । * शिवाद्या ऋषिपर्यन्ताः स्मर्तारोऽस्य न कारका इति वचनान्नास्ति कर्ता येषां तानि वैदिकानि इत्यर्थः । ६ रचनाविशेषाः । ७ बालस्य । ८ अनुचितापि । ९ अधीनम् १० प्रीणयति ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

व्योमेति बिन्दुरिति[1] नाद[2] इतीन्दुलेखा- ।
रूपेति वाग्भव[3]तनूरिति मातृ[4]केति ॥
निःष्यन्दमान[5]सुखबोधसुधास्वरूपा ।
विद्योतसे मनसि भाग्यवतां जनानाम् ॥ ३ ॥
आविर्भवत्पुलक[6]सन्ततिभिः शरीरै- ।
[7]र्निष्यन्दमानसलिलैर्नयनैश्च नित्यम् ॥
वाग्भिश्च गद्गदपदाभिरुपासते ये ।
पादौ तवाम्ब भुवनेषु त एव धन्याः ॥ ४ ॥
वक्त्रं यदु[8]द्यतमभिष्टुतये भवत्या- ।

---

१ ज्ञानं । २ विमर्शः । ३ वाग्बीजरूपा । ४ अकारादिक्षकारांता । ५ स्त्रवदानन्दज्ञानामृतरूपा । ६ रोमाञ्चः । ७ उपलक्षिताः । ८ उद्यमयुक्तम् उपरिकृतमित्यर्थः ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

स्तुभ्यं नमो यदपि देवि शिरः करोति ॥
चेतश्च यत्त्वयि परायणमम्ब तानि ।
कस्यापि कैरपि भवन्ति तपोविशेषैः ॥ ५ ॥
मूला[1]लवालकुहरादुदिता भवानि ।
निर्भिद्य षट्सरसिजानि तडिल्लतेव ॥
[2]भूयोऽपि तत्र विशसि ध्रुव[3]मंडलेन्दु- ।
निःष्यन्दमानपरमामृततोयरूपा ॥ ६ ॥
दग्धं यदा मदनमेकमनेकधा ते ।
[4]मुग्धः कटाक्षविधिर[5]ङ्कुरयांचकार ॥

१ मूलाधाररंध्रात् । २ अवरोहे । ३ अक्षीणमंडलब्रह्मरंध्रवर्तिन इन्दोः सकाशात् । ४ सुन्दरः । ५ जनयामास ।

CC-0. Narinder Safaya Collection. Digitized by eGangotri

धत्ते तदाप्रभृति देवि ललाटनेत्रं ।
सत्यं ह्रियेव मुकुलीकृतमिन्दुमौलिः[1] ॥ ७ ॥
अज्ञातसंभवमनाकलितान्ववायं[2] ।
भित्तुं कपालिनमवाससमद्वितीयम् ॥
पूर्वं करग्रहणमङ्गलतो[3] भवत्याः ।
शम्भुं क एव बुबुधे गिरिराजकन्ये! ॥ ८ ॥
चर्माम्बरं च शवभस्मविलेपनं च ।
भिक्षाटनं च नटनं च परेतभूमौ[4] ॥
वेतालसंहतिपरिग्रहता[5] च शम्भोः ।
शोभां बिभर्ति गिरिजे तव साहचर्यात् ॥ ९ ॥

१ निमीलितम् । २ अज्ञातकुलम् । ३ विवाहात् । ४ श्मशाने । ५ परिवारत्वम् ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

कल्पोपसंहरण[1]केलिषु पण्डितानि ।
चण्डानि खण्डपरशोरपि ताण्डवानि ॥
आलोकनेन तव कोमललितानि मात-
र्लास्यात्मना परिण[2]मन्ति जगद्विभूत्यै ॥ १० ॥
जन्तोरपश्चिमतनो[3]ः सति कर्मसाम्ये ।
निश्शेष[4]पाशपटलच्छिदुरा निमेषात् ॥
कल्याणि! दैशिक[5]कटाक्षसमाश्रयेण ।
कारुण्यतो भवसि शाम्भववेददीक्षा ॥ ११ ॥
मुक्ताविभूषणवती नवविद्रुमाभा ।

१ कल्पान्तक्रीडासु । २ रूपान्तरमापादयंति । ३ अग्रे जन्माभाववतः । ४ कलादिपाशसमूहच्छेत्री । ५ गुरुवरः ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

यच्चेतसि स्फुरसि तारकितेव सन्ध्या ॥

एकः स एव भुवनत्रयसुन्दरीणां ।
कन्दर्पतां व्रजति पञ्चशरीं विनापि ॥ १२ ॥

ये भावयन्त्यमृतवाहिभिरंशुजालै- ।
राप्याय्यमानभुवनाममृतेश्वरीं त्वाम् ॥

ते लङ्घयन्ति ननु मातरलङ्घनीयां ।
ब्रह्मादिभिः सुरवरैरपि कालकक्ष्याम् ॥ १३ ॥

यः स्फाटिकाक्षगुणपुस्तककुण्डिकाढ्यां ।
व्याख्यासमुद्यतकरां शरदिन्दुशुभ्राम् ॥

पद्मासनां च हृदये भवतीमुपास्ते ।

---

१ करणसंङ्क्रान्तैः स्वैश्चिन्मरीचिभिः । २ मर्यादाम् ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

मातः स विश्वकवितार्किकचक्रवर्ती ॥ १४ ॥

[१]बर्हावतंसयुतबर्बरकेशपाशां ।
[२]गुञ्जावलीकृतघनस्तनहारशोभाम् ॥
श्यामां प्रवाल[३]वदनां[++] सुकु[४]मारहस्तां ।
त्वामेव नौमि शबरीं शबरस्य जायाम् ॥ १५ ॥

अर्धेन किं नवलता[५]ललितेन मुग्धे ।
क्रीतं विभोः [६]परुषमर्धमिदं त्वयेति ।
[७]आलीजनस्य परिहासवचांसि मन्ये ।
मन्दस्मितेन तव देवि जडीभवन्ति ॥ १६ ॥

---

१ मयूरपिच्छम् । २ अरण्यजैः फलविशेषैः । ३ विद्रुमवत् । ४ कोमलकराम् ।
५ कोमलेन । ६ कठिनम् । ७ सखी । ++ रदनामित्यपि पाठः ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

ब्रह्माण्डबुद्बुद[1]कदम्बकसंकुलो[2]ऽयं ।
मायोदधिर्विविधदुःखतरङ्गमालः ॥
आश्चर्यमम्ब झटिति प्रलयं प्रयाति ।
त्वद्ध्यानसंततिमहावडवामुखाग्नौ ॥ १७ ॥

दाक्षायणीति कु[3]टिलेति गु[4]हारणीति ।
कात्यायनीति कमलेति कलावतीति ॥
एका सती भगवती परमार्थतोऽपि ।
संदृश्यसे बहुविधा ननु नर्तकीव ॥ १८ ॥

आनन्दलक्षणमनाह[5]तनाम्नि देशे ।

---

१ जलबिन्दुविकाराः । २ पूर्णः । ३ कुण्डलिनीरूपतया । ४ चिद्दीप्तिसंदीपिनीत्वात्
५ हृच्चक्रे ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

नादात्मना[1] परिणतं तव रूपमीशे ॥
प्रत्यङ्मुखेन[2] मनसा परिचीयमानं[3] ।
शंसन्ति नेत्रसलिलैः पुलकैश्च धन्याः ॥ १९ ॥
त्वं चन्द्रिका शशिनि तिग्मरुचौ रुचिस्त्वं ।
त्वं चेतनासि पुरुषे पवने बलं त्वम् ॥
त्वं स्वादुतासि सलिले शिखिनि त्वमूष्मा ।
निःसारमेतदखिलं त्वद्दृते[4] यदि स्यात् ॥ २० ॥
ज्योतींषि[5] यद्दिवि चरन्ति यदन्तरिक्षं ।
सूते पयांसि यदहिर्धरणीं च धत्ते ॥
यद्वाति वायुरनलो यदुदर्चिरास्ते ।

१ शब्दरूपेण । २ अन्तर्मुखेन । ३ अभ्यस्यमानम् । ४ त्वां विना । ५ ताराः ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

तत्सर्वमम्ब तव केवलमाज्ञयैव ॥ २१ ॥

सङ्कोचमिच्छसि यदा गिरिजे तदानीं ।
वाक्तर्कयोस्त्वमसि भूमिरनामरूपा[1] ॥
यद्वा विकासमुपयासि यदा तदानीं ।
त्वन्नामरूपगणनाः सुकरीभवन्ति ॥ २२ ॥

भोगाय देवि भवतीं कृतिनः प्रणम्य ।
भ्रूकिंकरीकृत[2]सरोजगृहासहस्राः ॥
चिन्तामणिप्रचय[3]कल्पितकेलिशैले ।
कल्पद्रुमोपवन एव चिरं रमन्ते ॥ २३ ॥

---

१ वाङ्मनोगोचरातीतेत्यर्थः । २ भ्रुवोः किंकरीकृतं भ्रूविक्षेपमात्रेणैव प्रणिहितं लक्ष्मीसहस्रं यैस्ते । ३ राशिः ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

हन्तुं त्वमेव भवसि त्वदधीनमीशे ।
संसारतापमखिलं दयया पशूनाम्[1] ॥
वैकर्तनी[2] किरणसंहतिरेव शक्ता ।
घर्मं निजं शमयितुं निजयैव वृष्ट्या ॥ २४ ॥
शक्तिः[3] शरीरमधिदैवतमन्तरात्मा[4] ।
ज्ञानं[5] क्रिया[6] करणमासनजालमिच्छा ॥
ऐश्वर्यमायतनमावरणानि च त्वं ।
किं तन्न यद्भवासि देवि शशाङ्कमौलेः ॥ २५ ॥
भूमौ निवृत्तिरुदिता पयसि प्रतिष्ठा ।

१ पश्यन्ति सामान्यवत्पशवो जीवाः । २ सावित्री । आदित्याज्जायते वृष्टिरित्युक्तेः । ३ परा चिद्रूपा शक्तिः । ४ जीवात्मा । ५ ज्ञानात्मकं मनः । ६ क्रियात्मकः प्राणः ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

विद्यानले मरुति शान्तिरतीतशान्तिः ॥
व्योम्नीति याः किल कला[1]ः कलयन्ति विश्वं ।
तासां विदूरतरमम्ब ! पदं[2] त्वदीयम् ॥ २६ ॥

यावत्पदं[3] पदसरोजयुगं त्वदीयं ।
नाङ्गीकरोति हृदयेषु जगच्छरण्ये ॥
तावद्विकल्पजटिला[4]ः कुटिलप्रकारा-
स्तर्कग्रहाः समयिनां[5] प्रलयं न यान्ति ॥ २७ ॥

यद्देवयान[6]पितृयानविहारमेके[7] ।

---

१ कला नाम जगत्कर्तृत्वरूपा शक्तिर्बहिर्मुखत्वमापन्ना। अत्र तु भूम्यादिपदैर्मूलाधारादि चक्राणि लक्ष्यन्ते । २ चैतन्यस्वरूपम् । ३ स्थानम् । ४ दुर्बोधाः । ५ मतवादिनाम् । ६ प्राणापानाभ्यामिडापिंगलयोः संचारं कृत्वा । ७ मुख्या योगिनः ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

कृत्वा मनः करणं[1]मंडलसार्वभौमम् ॥
[2]याने निवेश्य तव कारणपञ्चकस्य[3] ।
पर्वाणि पार्वति नयन्ति निजासनत्वम् ॥ २८ ॥

स्थूलासु मूर्तिषु महीप्रमु[5]खासु मूर्तेः ।
कस्याश्चनापि तव वैभवमम्ब यस्याः ॥
पत्या[6] गिरामपि न शक्यत एव वक्तुं ।
सासि स्तुता किल मयेति तितिक्षि[7]तव्यम् ॥ २९ ॥

कालाग्निकोटिरुचिमम्ब ! षडध्वशुद्धा- ।

---

१ इन्द्रियसमूहचक्रवर्तिनम् । २ शक्तिमार्गे । ३ शक्तेः पंचकारणासनत्वाच्छाक्तिस्वरूपा भवन्तीत्यर्थः । ४ शिरांसि । ५ मध्यात् । ६ ब्रह्मणापि । ७ क्षन्तव्यम् । ८ वर्णपदमंत्रतत्त्वभुवनकलाख्यषडध्वरूपदेहशोधने ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

वाप्लावनेषु भवतीममृतौघवृष्टिम् ॥
श्यामां घनस्तनतटां सकलीकृतौ[1] च ।
ध्यायन्त एव जगतां गुरवो भवन्ति ॥ ३० ॥

विद्यां परां कतिचिदम्बरमम्ब[2] केचि-[3] ।
दानन्दमेव कतिचित्[4] कतिचिच्च[5] मायाम्[6] ॥
त्वां विश्वमाहुरपरे[7] वयमामनाम[8] ।
साक्षादपारकरुणां गुरुमूर्तिमेव ॥ ३१ ॥

कुवलयदलनीलं बर्बरस्निग्धकेशं ।
पृथुतरकुचभाराक्रान्तकान्तावलग्नम्[9] ॥

---

१ चिद्रसाश्यानत्वेन देहोत्पादने । २ शून्यम् । ३ बौद्धाः । ४ वेदान्तिनः । ५ नैयायिकाः । ६ भेदप्रथाम् । ७ चार्वाकाः । ८ शाक्ताः । ९ मध्यम् ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

किमिह बहुभिरुक्तैस्त्वत्स्वरूपं परं नः ।
सकलभुवनमातः सन्ततं सन्निधत्ताम्[1] ॥ ३२ ॥

इति श्रीपञ्चस्तव्यां चतुर्थोऽम्बास्तवः
समाप्तः ।

---

१ सन्निहितं भवतात् ।

CC-0. Narinder Safaya Collection. Digitized by eGangotri

सकलजननीस्तवः पञ्चमः ॥

अजा[1]नन्तो यान्ति क्षयमवशमन्योन्यकलहै- ।
रमी मायाग्रन्थौ तव परि[2]लुठन्तः समयि[3]नः ॥
जगन्मातर्जन्मज्वरभयतमःकौमु[4]दि ! वयं ।
नमस्ते कुर्वाणाः शरणमुपयामो भगवतीम् ॥ १ ॥
वचस्तर्कागम्यस्वरसपर[5]मानन्दविभव- ।
प्रबोधाकाराय द्यु[6]तितुलितनीलोत्पलरुचे ॥
शिवस्याराध्याय स्तनभरविनम्राय सततं ।
नमो यस्मै कस्मैचन भवतु मुग्[7]धाय महसे ॥ २ ॥

---

१ त्वत्स्वरूपामिति शेषः । २ परिवर्तमानाः । ३ मतभेदवादिनः । ४ संबोधन
५ सूक्ष्मरूपेण । ६ स्थूलरूपेण । ७ मनोज्ञाय ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

लुठद्गुञ्जाहारस्तनभरनमन्म[1]ध्यलतिका- ।
मुद[2]ञ्चद्धर्माम्भःकण[3]गुणितनीलोत्पलरुचम् ॥
शिवं पार्थत्राणप्रवण[4]मृगयाकारगुणितं ।
शिवामन्वग्यान्तीं शवरमहमन्वे[5]मि शवरीम् ॥ ३ ॥
मिथः केशा[6]केशिप्रधननिधनास्तर्क[7]घटना- ।
बहुश्रद्धा भक्तिप्रणयविषयाश्चाप्तविधयः ॥
प्रसीद प्रत्यक्षीभव गिरिसुते! देहि शरणं ।
निरा[8]लम्बं चेतः परि[9]लुठति पारि[10]प्लवमिदम् ॥ ४ ॥
शुनां वा वह्नेर्वा खगपरि[11]षदो वा यदशनं ।

---

१ अवलम्बलताम् । २ निःसरत् । ३ उपशोभितम् । ४ अर्जुनरक्षातत्परेण मृगयाकारोचितेन वेषेण कृतशोभम् । ५ शरणं प्रपद्ये । ६ केशेषु केशेषु गृहीत्वा यद्युद्धं प्रवृत्तम् । ७ प्राप्तिः । ८ निराश्रयत्व... । ९ परिवर्तते । १० चंचलम् । ११ पंक्तेः ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

कदा केन क्वेति क्वचिदपि न कश्चित्कलयति[1] ॥
अमुष्मिन्विश्वासं विजहिहि[2] ममाहार्य[3] वपुषि ।
प्रपद्येथाश्चेतः सकलजननीमेव शरणम् ॥ ५ ॥

अनाद्यन्ताभेदप्रणयरसिकापि प्रणयिनी ।
शिवस्यासीर्यत्त्वं परिणयविधौ देवि ! गृहिणी ॥
सवित्री[5] भूतानामपि यदुदभूः[6] शैलतनया ।
तदेतत्संसारप्रणयन[7]महानाटकसुखम् ॥ ६ ॥

ब्रुवन्त्येके[8] तत्त्वं भगवति ! सदन्ये[9] विदुरसत् ।
परे[10] मातः ! प्राहुस्तव सदसदन्ये सुकवयः ॥

---

१ गणयति । २ त्यज । ३ मदीयमिदं वपुरिति विश्वासम् । ४ द्रुतम् । ५ उत्पादयित्री
६ उत्पन्ना । ७ संपादनं । ८ सांख्याः । ९ बौद्धाः । १० तार्किकाः ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

परे[1] नैतत्सर्वं समभिदधते देवि! सुधिय- ।
स्तदेतत्त्वन्मायाविलसितमशेषं ननु शिवे! ॥ ७ ॥

तडित्कोटिज्योतिर्द्युतिदलितषड्ग्रन्थि[2]गहनं ।
प्रविष्टं स्वाधारं[3] पुनरपि[4] सुधावृष्टिवपुषा ॥
किमप्यष्टात्रिंशत्[5]किरणसकलीभूतमनिशं ।
भजे धाम श्यामं कुचभरनतं बर्बरकचम् ॥ ८ ॥

चतुष्पत्रान्तः षड्दल[6]भगपुटान्तस्त्रिवलय- ।
स्फुरद्विद्युद्वह्निद्युमणिनियुता[7]भद्युतियुते! ॥

---

१ वेदान्तिनः । न सत्तन्नासदुच्यते इति श्रुतेः । २ षट्चक्राण्येव वनम् । ३ मूलाधारम् । ४ अवरोहे । ५ द्वादशकिरणप्राणसूर्यरूपेण षोडशकिरणापानसोमरूपेण दशकिरणोदानानलरूपेण । ६ षट्कोणत्रिकोणमध्ये । ७ असंख्याः ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

षडश्रं[1] भित्त्वादौ दशदलमथ[2] द्वादशदलं[3] ।
कलाश्रं[4] च द्व्यश्रं[5] गतवति[6] ! नमस्ते गिरिसुते ॥ ९ ॥
कुलं[7] केचित्प्राहुर्वपुरकुलमन्ये[8][9] तव बुधाः ।
परे *तत्सम्भेदं समभिदधते कौलमपरे[10] ॥
चतुर्णामप्येषामुपरि किमपि प्राहुरपरे ।
महामाये[11] ! तत्त्वं तव कथममी निश्चिनुमहे ॥ १० ॥
षडध्वारण्यानीं[12] प्रलयरविकोटिप्रतिरुचा[13] ।

---

१ षड्दलं स्वाधिष्ठानचक्रम् । २ मणिपूरकम् । ३ अनाहतचक्रम् । ४ विशुद्धिचक्रम् ५ आज्ञाचक्रम् । ६ ब्रह्मरंध्रं प्राप्तवति । ७ षट्त्रिंशत्तत्त्वात्मकम् । ८ स्वरूपम् । ९ परमशिवरूपम्. * तयोः संयोगरूपम् । १० शक्तिरूपम् । ११ विद्यातत्त्वादारभ्य शिवतत्त्वं वा द्व्यात्मिका [illegible] । १२ मार्गादयः । १३ सदृशया ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

रुचा भस्मीकृत्य स्वपदकमलप्रह्व[1]शिरसाम् ॥
वितन्वानः शैवं किमपि वपुरिन्दीवररुचिः ।
कुचाभ्यामानम्रः शिवपु[2]रुषकारो विजयते ॥ ११ ॥

प्र[3]काशानन्दाभ्यामविदित[4]चरीं मध्य[5]पदवीं ।
प्रविश्यैतद्द्व[6]न्द्वं रविशशिसमाख्यं कवलयन्[7] ॥
प्रविश्योर्ध्वं[8] नादं लयद[9]हनभस्मीकृतकुलः ।
प्रसादात्ते जन्तुः शिवम[10]कुलमम्ब ! प्रविश[11]ति ॥ १२ ॥

प्रियङ्गुश्यामाङ्गीमरुणतरवासःकिसलयां ।

---

१ नम्रम् । २ अहमित्येवंरूपा शक्तिः । ३ चिद्विमर्शाभ्याम् । ४ ज्ञानात्पूर्वमविदिताम् । ५ सुषुम्णामार्गम् । ६ प्राणापानाख्यम् । ७ चिद्रूपेविलापयन् । ८ सर्वोत्तीर्णं ब्रह्मरन्ध्रम् । ९ चिद्विश्रान्तिवह्निना विस्मारितदेहाहंभावः । १० तत्त्वोत्तीर्णं । ११ चिद्रूपे निलीनो भवति ।

CC-0. Narinder Safaya Collection. Digitized by eGangotri

सं[1]मुन्मीलन्मुक्ताफलबहुलनेपथ्यकुसुमाम् ॥
स्तनद्वन्द्वस्फारस्तबकनमितां कल्पलतिकाम् ।
सकृद्ध्यायन्तस्त्वां दधति शिवचिन्तामणिपदम् ॥१३॥
षडा[2]धारावर्तैरपरिमितमन्त्रोर्मिपटलैः ।
श्चलन्मुद्राफेनैर्बहुविधलसद्दैवतझ[3]षैः ॥
क्रमस्रोतोभिस्त्वं वहसि परनादामृतनदी[4] ।
भवानि ! प्रत्यग्रा शिवचिदमृताब्धिप्रणयिनी ॥ १४ ॥
महीपाथो[5]वह्निश्वसनवियदात्मे[6]न्दुरविभिः ।
वपुर्भि[7]र्ग्रस्तांशैर[8]पि तव कियानम्ब ! महिमा ॥

---

१ विलसत् । २ षडाम्नायजलभ्रमैः । ३ मत्स्यैः । ४ पूर्णविमर्शामृतनदी । ५ जलम् । ६ यजमानः । ७ मूर्तिभिः । ८ अंशविभागरहितैः पूर्णैरित्यर्थः

CC-0. Narinder Safaya Collection. Digitized by eGangotri

अमून्यालोकयन्ते भगवति ! न कुत्राप्यणुतरा- ।
मवस्थां प्राप्तानि त्वयि तु पर[1]मव्योमवपुषि ॥ १५ ॥
मनुष्यास्तिर्यञ्चो मरुत इति लोकत्रयमिदं ।
भवाम्भोधौ मग्नं त्रिगुणलहरीकोटिलुठितम् ॥
कटाक्षश्चेदत्र क्वचन तव मातः ! करुणया ।
शरीरी सद्योऽयं व्रजति परमानन्दतनुताम् ॥ १६ ॥
[2]कलां प्र[3]ज्ञामाद्यां स[4]मयम[5]नुभूतिं समरसां ।
गुरुं पारम्[6]पर्यं विनयमुपदेशं शिवकथाम् ॥
प्रमाणं निर्वाणं परममतिभूतिं परगुँहां ।

---

१ परमाकाशस्वरूपायाम् । २ क्रियाशक्तिम् । ३ ज्ञानशक्तिम् । ४ सदाचारम् । ५ इदमहमित्येवंरूपमनुभवम् । ६ परम्परोपदेशम् । ७ मायाख्याम् ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

विधिं विद्यामाहुः सकलजननीमेव मुनयः ॥ १७ ॥

प्रलीने शब्दौघे[1] तदनु विरते बिन्दुविभवे[2] ।
ततस्तत्त्वे[3] चाष्टध्वनिभिरनुपाधिन्युपरते[4] ॥
श्रिते शाक्ते पर्वण्यनुकलितचिन्मात्रगहनां[5] ।
स्वसंवित्तिं योगी रसयति[6] शिवाख्यां परतनुम्[7] ॥१८॥

परानन्दाकारां निरवधिशिवैश्वर्यवपुषं ।
निराकारज्ञानप्रकृतिम्[8]अनवच्छिन्नकरुणाम् ॥
सवित्रीं[9] भूतानां निरतिशयधामास्पदपदां[10] ।
भवो वा मोक्षो वा भवतु भवतीमेव भजताम् ॥१९॥

---

१ प्रत्याहारेण निवृत्ते शब्दादिविषयौघे । २ ऐन्द्रियिकज्ञानविस्तारे । ३ चिदात्मपरामर्शे ।
४ अकचटतपयशाष्टकवर्गात्मकध्वनिभिः । ५ अन्ववशिष्टचिन्मात्रदुरवगाहां । ६ चमत्करोति
७ उत्कृष्टं स्वरूपम् । ८ योनिम् । ९ उत्पादयित्रीम् । १० परमाशिवस्वरूपाम् ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

जगत्कायं[1] कृत्वा तदपि[2] हृदये तच्च[3] पुरुषे ।
पुमांसं बिन्दुस्थं[4] तदपि[5] परनादाख्यगहने ॥
तदेतज्ज्ञानाख्ये[6] तदपि[7] परमानन्दविभवे ।
महाव्योमाकारे[8] त्वदनुभवशीलो[9] विजयते ॥ २० ॥

विधे विद्ये वेद्ये विविधसमये[10] वेदजननि ।
विचित्रे विश्वाद्ये विनयसुलभे वेदेंगुलिके[11] ॥
शिवाज्ञे शीलस्थे शिवपदवदान्ये[12] शिवनिधे ।

---

१ भावनया ध्यात्वा । २ कायम् । देहसारत्वात् । ३ तच्च हृदयम् । तदाश्रयत्वात् । ४ ज्ञानाश्रयम् । ५ तं बिन्दुमपि चिद्रूपे महाशून्ये । ६ शून्यं स्वात्मपरामर्शरूपे । ७ ज्ञानं स्वात्मप्रकाशानन्दमये । ८ हे महाशून्यरूपे । ९ योगी । १० नानासिद्धान्तभूते । ११ चतुर्वेदसारभूते । १२ दात्रि ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

शिवे मातर्मह्यं त्वयि वितर भक्तिं निरुपमाम् ॥२१॥

विधेर्मुण्डं[1] हृत्वा यदकुरुत पात्रं[2] करतले ।
हरिं शूलप्रोतं यदगमयदंसाभरणताम् ॥
अलंचक्रे कण्ठं यदपि गरलेनाम्ब गिरिशः ।
शिवस्थायाः शक्तेस्[3]तादिदमखिलं ते विलसितम् ॥ २२ ॥

विरिञ्च्याख्या मातः! सृजसि हरिसंज्ञा त्वमवसि ।
त्रिलोकीं रुद्राख्या हरसि विदधासीश्वरदशाम्[4] ॥
भवन्ती सादाख्या[5] शिवयसि च पाशौघदलिनी[6] ।
त्वमेवैकानेका भवसि कृतभेदैर्गिरिसुते ॥ २३ ॥

१ ब्रह्मणः शिरः । २ कपालस्वरूपम् । ३ सामर्थ्यरूपायाः । ४ ईश्वरस्वरूपम् । ५ सदाशिवरूपा शिवात्मकतां सम्पादयसि । ६ कलादिपाशसमूहं खण्डयित्री ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

मुनीनां चेतोभिः प्रमृदितकषायैरपि मनाग् ।
अशक्ये संस्प्रष्टुं चकितचकितैरम्ब सततम् ॥
श्रुतीनां मूर्धानः प्रकृतिकठिनाः कोमलतरे ।
कथं ते विन्दन्ते पदकिसलये पार्वति पदम् ॥ २४ ॥
तडिद्वल्लीं नित्याममृतसरितं पाररहितां ।
मलोत्तीर्णां ज्योत्स्नां प्रकृतिमगुणग्रन्थिगहनाम् ॥
गिरां दूरां विद्यामविनतकुचां विश्वजननी- ।
मपर्यन्तां लक्ष्मीमभिदधति सन्तो भगवतीम् ॥२५॥
शरीरं क्षित्यम्भःप्रभृतिरचितं केवलमिदं ।

---

१ नाशितरागद्वेषमोहैः । २ अतिभीतैः । ३ उपनिषदात्मकाः । ४ स्वभावतो दुर्बोधाः । ५ मलरहिताम् । ६ मायाम् । ७ गुणाः सत्त्वादयः । ८ वृद्धामित्यर्थः । ९ जडस्वरूपामित्यर्थः ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

सुखं दुःखं चायं कलयति[१] पुमांश्चेतन[२] इति ॥
स्फुटं[३] जानानोऽपि प्रभवति न देही रहयितुं[४] ।
शरीराहंकारं तव समय[५]बाह्यो गिरिसुते ॥ २६ ॥
पिता माता भ्राता सुहृदनुचरः सद्म गृहिणी ।
वपुः पुत्रो मित्रं धनमपि यदा[६] मां विजहति ॥
तदा मे भिन्दाना सपदि भयमोहान्धतमसं[७] ।
महाज्योत्स्ने[८] मातर्भव करुणया सान्निधिकरी ॥ २७ ॥
सुता दक्षस्यादौ[९] किल सकलमातस्त्वमुदभूः[१०] ।

---

१ अनुभवति . २ चेतनत्वादित्यर्थः . ३ देहचिदात्मनोर्भेदम् . ४ त्यक्तुम् . ५ त्वदनुग्रहबहिर्भूतः . ६ परलोकोन्मुखगमनावसरे . ७ गाढध्वान्तम . ८ चन्द्रादिज्योतिषां प्रकाशकारिणीत्वात् महाज्योत्स्नात्वम् । ९ दक्षप्रजापतेः । १० समजनि ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

[1]सदोषं तं हित्वा तदनु गिरि[2]राजस्य तनया ॥
अनाद्यन्ता शम्भोरपृथगपि शक्तिर्भगवती ।
विवाहाज्जाया[3]सीत्य[4]हह चरितं वेत्ति तव कः ॥२८॥
[5]कणास्त्वद्दीप्तीनां रविशशिकृशानुप्रभृतयः ।
परं ब्रह्म क्षुद्रं तव नियतमानन्दकणिका ॥
शिवादि क्षित्यन्तं त्रिवलयतनोः सर्व[6]मुदरे ।
तवास्ते भक्तस्य स्फुरसि हृदि चि[7]त्रं भगवति ॥२९॥
त्वया यो [8]जानीते रच[9]यति भवत्यैव सततं ।

---

१ सापराधम् । २ हिमालयस्य । ३ भवसि । ४ अहहेत्याश्चर्ये । ५ लेशाः । ६ अनेन भगवत्या अतिविशालता सूचिता । ७ यस्यां सर्वं माति तस्या हृदयैकदेशे स्फुरणमत्याश्चर्यकारीत्यर्थः । ८ इति ज्ञानशक्तिस्त्वमेव । ९ क्रियाशक्तिरपि त्वमेव ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

त्वयैवेच्छ[1]त्यम्ब ! त्वमसि निखिला यस्य[2] तनवः ॥
[3]गतः स्वाम्यं शम्भुर्वहति परमं व्योम भवती ।
तथाप्येवं हित्वा विहरति शिवस्येति किमिदम् ॥३०॥
पुरः पश्चादन्तर्बहिरपरिमेयं परिमितं ।
परं स्थूलं सूक्ष्मं [4]सकुलम[5]कुलं गुह्यमगुहम् ॥
[6]दवीयो [7]नेदीयः सदसदिति विश्वं भगवतीं ।
सदा [8]पश्यन्त्याज्ञां वहसि भुवनक्षोभजननीम् ॥ ३१ ॥

---

१ इच्छाशक्तिरपि त्वमेव । २ शिवस्याष्टौ मूर्तयः । ३ परमं व्योम शून्यरूपत्वं गतः प्राप्तोऽपि स्वाम्यं शक्तिमत्वं शंभुर्वहति तथाप्येवं शिवस्य शून्यरूपत्वं हित्वोपेक्ष्य भवती शिवस्य सम्बन्धिनी शक्तिरहमिति विहरति क्रीडति इति यदभावस्य भावत्वसम्पादनं तदतीवाश्चर्यम् । ४ जगत् । ५ शिवः । ६ दूरम् । ७ निकटम् । ८ साक्षात्कुर्वन्ति ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

मयूखाः पूष्णीव[1] ज्वलन इव तद्दीप्तिकणिकाः ।
पयोधौ कल्लोलप्रतिहितमहिम्नीव पृषतः[2] ॥
उदेत्योदेत्याम्ब त्वयि सह निजैस्तात्त्विककुलै-[3] ।
र्भजन्ते तत्त्वौघाः[4] प्रशममनुकल्पं परवशाः[5] ॥ ३२ ॥
विधुर्विष्णुर्ब्रह्मा प्रकृतिरणुरात्मा[6][7] दिनकरः ।
स्वभावो जैनेन्द्रः सुगतमुनिराकाशमनिलः ॥
शिवः शक्तिश्चेति श्रुतिविषयतां तामुपगतां ।
विकल्पैरेभिस्त्वामभिदधति सन्तो भगवतीम् ॥ ३३ ॥
प्रविश्य स्वं मार्गं[8] सहजदयया देशिकदृशा[9] ।

---

१ सूर्ये । २ बिन्दवः । ३ तत्त्वानां स्वस्वकार्यसमूहैः । ४ शिवादयः । ५ त्वदधीनाः । ६ जीवः
७ परमात्मा । ८ सुषुम्णामार्गम् । ९ गुरुवरानुग्रहदृष्ट्या ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

षडध्वध्वान्तौघच्छिदुरगणनातीतकरुणाम् ॥
परानन्दाकारां सपदि शिवयन्तीमपि तनुं ।
स्वमात्मानं धन्याश्चिरमुपलभन्ते भगवतीम् ॥ ३४ ॥
शिवस्त्वं शक्तिस्त्वं त्वमसि समया त्वं समयिनी ।
त्वमात्मा त्वं दीक्षा त्वमयमणिमादिर्गुणगणः ॥
अविद्या त्वं विद्या त्वमसि निखिलं त्वं किमपरं ।
पृथक्तत्त्वं त्वत्तो भगवति न वीक्षामह इमे ॥ ३५ ॥
असंख्यैः प्राचीनैर्जननि जननैः कर्मविलया- ।
द्धते जन्मन्यन्तं गुरुवपुषमासाद्य गिरिशम् ॥
अवाप्याज्ञां शैवीं क्रमतनुरपि त्वां विदितवान् ।

---

१ भुवनाद्यध्वरूपः संसारः । २ आनन्दयन्तीम् । ३ कर्मलोपात् । ४ गुरुस्वरूपम् ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

नयेयं त्वत्पूजास्तुतिविरचनेनैव दिवसान् ॥ ३६ ॥
यत्षट्पत्रं कमलमुदितं तस्य या कर्णिकाख्या ।
योनिस्तस्याः प्रथितमुदरे यत्तदोङ्कारपीठम् ॥
तस्मिन्नन्तः कुचभरनतां कुण्डलीतः प्रवृत्तां ।
श्यामाकारां सकलजननीं सन्ततं भावयामि ॥ ३७ ॥
भुवि पयसि कृशानौ मारुते खे शशाङ्के ।
सवितरि यजमानेऽप्यष्टधा शक्तिरेका ॥
वहति कुचभराभ्यां या विनम्रापि विश्वं ।
सकलजननि सा त्वं पाहि मामित्यवश्यम् ॥ ३८ ॥

इति श्रीपंचस्तव्यां सकलजननीस्तवः पंचमः ।

समाप्ता चेयं पञ्चस्तवी ।

CC-0. Narinder Safaya Collection. Digitized by eGangotri

ॐ संसारसागरमहं तरितुं सुनौकां राज्ञीं नमामि शिरसा शिवसुन्दरीं त्वाम् ॥ सर्वेश्वरीं सकललोकसुखप्रदात्रीं त्वामेव देवि सततं शरणं प्रपद्ये ॥ १ ॥ मातः पयोधरयुगं पिबतु त्वदीयं नागाननर्तुमुखवत्सलपुत्रयुग्मम् ॥ निर्णेजनाम्बु न इह स्पृहयाम्यहं तु त्वत्पादपद्मयुगलस्य भवाग्निशान्त्यै॥२॥ मातस्त्वदीयपरितोषविशेषलब्धे छत्रे प्रहृष्यतु सदा भगवान्सुरेद्रः ॥ पीयूषवर्षणकरात्तव देवि पादच्छत्राद्विना किमपि राज्ञि न नाम याचे ॥ ३ ॥ मोहाटवीविकटसंकटपीडितोऽहं राज्ञि प्रपन्नपरमार्तिहरा त्वमेका ॥ जाज्वल्यतेऽम्ब हृदयार्तिकरो ममान्तः पापाग्निरेशि शमयैनममास्वरूपे ॥ ४ ॥ आरारटीमि करुणं भवतापतप्तः प्रोल्लालपीमि पतितो भव-

CC-0. Narinder Safaya Collection. Digitized by eGangotri

दुःखासिन्धौ ॥ मोमोर्मि राज्ञि लुठितो भवसर्पदष्टस्त्वाम-
न्तरेण शरणं मम कः शरण्ये ॥ ५ ॥ राज्ञि प्रपन्नवरदे सुकृ-
तादपर्णां त्वामाश्रितोऽस्मि सुचिरात्तुमहद्भिचित्रम् ॥ किं
नास्मि भैरवि ऋणैस्त्रिविधैर्विमुक्तः पाशैरिवोत्कटविषाक्तभुज-
ङ्गमानाम् ॥ ६ ॥ राज्ञि प्रसीद नतसौख्यकरे मृडानि रुद्राणि
रोगहरणे चतुरे प्रसीद ॥ शर्वाणि सर्वजनपापहरे प्रसीद
गौरि प्रसीद गुणगौरि शिवे प्रसीद ॥ ७ ॥ कल्याणि राज्ञि
जगदीश्वरि विश्वमातस्त्वामन्तरेण नहि देवि सुखं जनस्य ॥
पुत्रस्य दुःखहरणे सततोद्यता द्राक् मातैव हि स्नुतकुचा नु
भवत्यवश्यम् ॥ ८ ॥ राज्ञ्यष्टकमिदं पुण्यं यः पठेद्धर्षपूरितः ॥
सोऽत्र द्राक् प्राप्नुयात्कामान्परलोके च स्वर्गतिम् ॥ ९ ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

नाथ्यते यारमानाथोमानाथेन्द्रादिभिः सुरैः ॥ अनाथरक्षासिका सा भूयात्सर्वेप्सितप्रदा ॥ १० ॥

इति श्रीराज्ञीस्तुतिः समाप्ताऽनाथक्षेमाय भवतु ॥

श्रीराज्ञीस्तोत्रम् ।

ॐ ॐकाररूपेऽखिलवेदसारे वेदान्तविज्ञानचणैः प्रगीते॥
मूर्धा महाराज्ञि महार्हपीठे वन्दे त्वदीयं चरणारविन्दम् ॥१॥
भूरादिलोके कृतलक्षणेऽजे राज्ञि प्रपन्नार्तिहरे नमस्ते ॥ आक्रन्दमाकर्णय मे शरण्ये भक्तार्तिनाशे ह्यपरः प्रभुः कः ॥२॥
भुवोऽवकाशे रविचन्द्रदीप्तिर्देदीप्यते त्वामनु चित्प्रदीप्तिम् ॥
तमःप्रपञ्चं प्रविलाप्य हार्दं पद्मं ममाबोधय राज्ञि मातः ॥ ३ ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

स्वःशाखिदर्पं हरतीष्टदानादाशाधिकाद्यत्स्मृतमात्रमेव ॥ मा-
तर्महाराज्ञि तदाननं ते वन्दे शरत्सुन्दरचन्द्ररम्यम् ॥ ४ ॥
तद्वाङ्मनोदूरमचिन्तनीयं रूपं स्वकीयं भवदुःखहारि ॥ पी-
यूषपीयूषमयूखतुल्यं राज्ञि प्रकाशयाम्ब कदा दयेथाः ॥ ५ ॥
सवितुः शक्तिभूता त्वं सूयसेऽदश्चराचरम् ॥ नमोऽस्तु ते
महाराज्ञि पाहि मां शरणागतम् ॥ ६ ॥ वरेण्यं त्वत्पदाभ्य-
र्चामृतचर्वणमस्तु मे ॥ नमो० ॥ ७ ॥ भर्गो भर्गेऽपि संसार-
भर्जको यस्तवैव सः ॥ नमो० ॥ ८ ॥ देवस्य त्रिपुराराातेराहो-
पुरुषिके शिवे ॥ नमो० ॥ ९ ॥ धीमहिम्नापि केनापि यां
स्तोतुं न प्रभूयते ॥ नमो० ॥ १० ॥ धियो मे घोरसंसारलं-
घने सन्तु सज्जिताः ॥ नमो० ॥ ११ ॥ योऽर्चति त्वां स

CC-0. Narinder Safaya Collection. Digitized by eGangotri

देवेशि मघवादिभिरर्च्यते ॥ नमो० ॥ १२ ॥ नस्तितोऽद्रव-
दम्बाहं कर्मपाशैः प्रपीडितः ॥ नमो० ॥ १३ ॥ प्रचोदयात्त-
वेच्छा मां तवैवाङ्घ्रिनिषेवणे ॥ नमो० ॥ १४ ॥ राज्ञीस्तोत्र-
मिदं पुण्यं यः पठेद्भक्तिसंयुतः ॥ तस्य सिध्यति सर्वेष्टम-
चिराद्देवदुर्लभम् ॥ १५ ॥

इति द्वितीयं श्रीराज्ञीस्तोत्रं समाप्तमनाथक्षेमाय भवतु ।

मातुः स्नेहः सर्वपुत्रेषु तुल्यः श्लाघ्याश्लाघ्येष्वम्ब चे-
त्सत्यमेतत् ॥ दुर्वृत्तस्याप्यात्मजस्यास्ति किं मे त्यागो युक्त-
स्तर्हि दोषौघहर्त्रि ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

ॐ अष्टादशायुधवराढ्यभुजैर्युता या त्रातुं समस्तभुव-
नानि विपद्भयेभ्यः ॥ जागर्त्यशेषजनदुःखहरा परा सा श्रीशा-
रिका दिशतु मङ्गलसन्ततिं नः ॥ १ ॥ उद्यत्सहस्ररविभा-
स्वरदीप्तिदीप्तां सिंहासनां शशिकलाभरणां त्रिनेत्राम् ॥ यां
चिन्तयन्ति बहुभक्तिरसार्द्रचित्ताः श्रीशारिका० ॥ २ ॥ य-
त्पादयोः सकृदपीह कृतार्चनो ना भक्त्यान्वितो ह्यनुभव-
त्यमरप्रभुत्वम् ॥ श्रीराजराजसखिसौख्यनिवासभूमिः श्री-
शारिका० ॥ ३ ॥ सौदामनीप्रमदमत्तगजेन्द्रकर्णस्थित्या समापि
भजते स्थिरतां विभूतिः ॥ यत्पादपङ्कजयुगाश्रयणात्सदा
सा श्रीशारिका० ॥ ४ ॥ यत्कीर्तनश्रवणसंमननोत्थपुण्यं शक्नो-
ति नो गणयितुं बहुधाप्यनन्तः ॥ साऽशेषरोगदलनाय धृतौ-

CC-0. Narinder Safaya Collection. Digitized by eGangotri

षधीशा श्रीशारिका० ॥ ५ ॥ श्रीमातृकाभिरुपसेवितपादधूल्या प्रद्युम्नपीठसमवस्थितया यथेश्या ॥ काश्मीरदेशजनता परिपाल्यते सा श्रीशारिका० ॥ ६ ॥ यस्याः प्रदक्षिणपरिक्रमणात्सुभक्त्या पापोऽप्यलंघ्य भवसागरपारमेति ॥ सा शोकमोहपरितापविपत्तिहर्त्री श्रीशारिका० ॥ ७ ॥ मूलालवालमणिपूरकनाभिपद्महृत्कण्ठशिष्टिमतिवाह्य करन्ध्रमेत्य ॥ या मोदते सह शिवेन सहस्रपत्रे श्रीशारिका० ॥ ८ ॥ यस्या अनाहतनिनादसुधारसेन स्नातः परात्परसुखानुभवात्प्रहृष्टः ॥ जीवंश्च मुक्त इव भाति नरोत्तमः सा श्रीशारिका० ॥ ९ ॥ यद्देहसंगतिरसेन सुधापरार्धधिक्कारकेण विषधारणशक्तियुक्तः ॥ श्रीनीलकण्ठ इति कीर्तिमवाप शंभुः श्रीशारिका दिशतु मं-

CC-0. Narinder Safaya Collection. Digitized by eGangotri

गलसंततिं नः ॥ १० ॥ अमे सुरेशि योगीन्द्रामृतपायनतत्परे ॥ श्रीशारिके नमस्तेऽस्तु पाहि मां शरणागतम् ॥११॥ कामे कामितकामानां पूरणे पूर्णताप्रदे ॥ श्रीशारिके० ॥१२॥ चार्वङ्गि कोटिकन्दर्पलावण्ये विश्वमोहिनि ॥ श्रीशारिके० ॥ १३ ॥ टङ्कधारिणि शत्रूणां तिलशो देहखण्डिनि ॥ श्रीशारिके० ॥ १४ ॥ तारे निसर्गगम्भीरभवसागरतारिणि ॥ श्रीशारिके० ॥ १५ ॥ पार्वति त्रिजगन्मातर्हिमवद्वंशपावने॥ श्रीशारिके० ॥ १६ ॥ यक्षिणीष्टाष्टसिद्धीनां दायिनि देवपूजिते ॥ श्रीशारिके० ॥ १७ ॥ सत्त्वादिशबलेऽनन्तब्रह्माण्डजननीश्वरि ॥ श्रीशारिके० ॥ १८ ॥ कलानिधिकलाकान्तकिरीटकुण्डलोज्ज्वले ॥ श्रीशारिके० ॥ १९ ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

श्रीशारिका जगन्माताऽनाथनाथा सुरेश्वरी ॥ प्रीयतां पाद-
योरेतत्स्तोत्रपुष्पसमर्पणात् ॥ २० ॥

इति श्रीशारिकास्तोत्रं समाप्तम् ।

—o:*:*:*:o—

श्रीज्वालामुखीस्तोत्रम् ।

ॐ जाज्वल्यमानवपुषा दशदिग्विभागान्सन्दीपयन्त्य-
भयपद्मगदावराढ्या ॥ सिंहस्थिता शशिकलाभरणा त्रिनेत्रा
ज्वालामुखी हरतु मोहतमः सदा नः ॥ १ ॥ आब्रह्मकीट-
जननीं महिषीं शिवस्य मुग्धास्मितां प्रलयकोटिरविप्रकाशाम्॥
ज्वालामुखीं कनककुण्डलशोभितांसां वन्दे पुनः पुनरपीह
सहस्रकृत्वः ॥ २ ॥ देदीप्यमानमुकुटद्युतिभिश्च देवैर्दासैरिव

CC-0. Narinder Safaya Collection. Digitized by eGangotri

द्विगुणिताङ्घ्रिनखप्रदीप्तिम् ॥ ज्वालामुखीं सकलमङ्गलमङ्गलां
तामम्बां नतोऽस्म्यखिलदुःखविपत्तिदग्धीम् ॥ ३ ॥ नित्य-
हुताशपवनाम्बरसूर्यचन्द्रयष्ट्राख्यमूर्तिममलानपि पावय-
न्तीम् ॥ ज्वालामुखीं प्रणतकल्पलतां शिवस्य साम्राज्यश-
क्तिमतुलां महतीं नमामि ॥ ४ ॥ नौमीश्वरीं त्रिजगतोऽभ-
यदानशौण्डां ज्वालामहार्यभवजालहरां नमामि ॥ मोहान्ध-
कारहरणे विमलेन्दुकान्तिं देवीं सदा भगवतीं मनसा स्म-
रामि ॥ ५ ॥ दुष्कर्मवायुभिरितस्तत एव दीप्तैः पापज्वल-
ज्ज्वलनजातशिखाकलापैः ॥ दग्धं च जीवयतु मां परितो
लुठन्तं देवी दयार्द्रहृदयामृतपूर्णदृष्ट्या ॥ ६ ॥ ज्वालामुखी
ज्वलदनल्पलयाग्निकोटिरोचिष्मती रविशशिप्रतिभानकर्त्री ॥

CC-0. Narinder Safaya Collection. Digitized by eGangotri

भक्तस्य भर्गवपुषा भवभर्जनाय भूयात्सदाऽभ्युदयदानवदा-
न्यमुख्या ॥ ७ ॥ त्वं चौषधीशमुकुटाऽहमसाध्यरोगस्त्वं चि-
त्प्रदीप्तिरहमत्र भवांध्यमग्नः ॥ त्वं चाम्ब ! कल्पतरुरेवमहं च
भिक्षुर्ज्वालामुखि प्रकुरु देवि यथोचितं मे ॥ ८ ॥ यद्ध्यान-
केसरिसमाक्रमणोत्थभीतेर्मर्मव्यथाजनकदुःखशतानि सद्यः ॥
गोमायवन्ति परितो भृशकान्दिशीकानस्मांश्च पालयतु सैव
भवाब्धिदुःखात् ॥ ९ ॥ ज्वालामुखि क्षणमपीह विलम्बमम्ब
नार्तो ह्यनर्थपतितः सहते विपन्नः ॥ हस्तस्थितामृतकमण्ड-
लुवारिणैव मां मूर्च्छितं झटिति जीवय तापतप्तम् ॥ १० ॥
बाह्यान्ध्यनाशनविधौ रविचन्द्रवह्निज्योतींषि देवि दययाऽज-
नयः पुरा त्वम् ॥ एतत्तु रूपमखिलान्तरमोहरात्रिध्वान्ता-
CC-0. Narinder Safaya Collection. Digitized by eGangotri

न्तकारि तव यत्स्फुरतादतोऽन्तः ॥ ११ ॥ मन्ये त्रिधामनयने नयनत्रयं ते भक्तार्तिनाशननिमित्तविलोकनाय ॥ मातः परं यदपि देवि तथाप्ययऽधन्यस्त्वदृष्टिपातरहितोस्म्यहहा हतोऽस्मि ॥ १२ ॥ सत्यं ब्रवीमि शृणु चित्त मदान्ध मूर्ख मा गाः कदापि विषयान्विषमान्विषाक्तान् ॥ ईशीमपारकरुणां भवभीतिभेत्रीमम्बां भजस्व सततं परसौख्यदात्रीम् ॥१३॥ त्वं मे महेशि जननी मरमार्तिहर्त्री त्वं मे पिता हिततमस्त्वमहेतुबंधुः ॥ त्वं मे भवाब्धितरणे दृढनौस्त्वमेव दुःखामयाधिहरणे चतुरश्च वैद्यः ॥ १४ ॥ ज्वालां जगज्जननसंहरणस्थितीनां हेतुं गतिं मुषितलज्जितदुःखितानाम् ॥ उन्मोचनां च भवबंधनदुर्गतीनां त्वां नौमि नौमि शरणं शरणागता-

CC-0. Narinder Safaya Collection. Digitized by eGangotri

नाम् ॥ १५ ॥ ज्वलामुखीस्तवमिमं शृणुयात्पठेद्वा यः श्रद्धया परमया बहुभक्तियुक्तः ॥ भूयात्स दग्धबहुजन्मशतार्जिताऽघोऽनाथोप्यनेकजननाथितराज्यसंपत् ॥ १६ ॥

इति श्रीज्वालामुखीस्तोत्रं समाप्तम् ।

CC-0. Narinder Safaya Collection. Digitized by eGangotri

CC-0. Narinder Safaya Collection. Digitized by eGangotri

CC-0. Narinder Safaya Collection. Digitized by eGangotri

CC-0. Narinder Safaya Collection. Digitized by eGangotri

CC-0. Narinder Safaya Collection. Digitized by eGangotri

CC-0. Narinder Safaya Collection. Digitized by eGangotri

...ge and the contractor shall ensure that throughout the period of their occupation the...
...hut proper ventilation.

...shall be provided with suitable eaves for security purposes.

...of at least 8 yards between the rows of huts which may be reduced to 20 ft. accord...
...neer-in-charge, back to back construction will be allowed.

...hall provide adequate supply of water for the use of labourers. The provision shall not...
...head per day for drinking purposes and 3 gallons of clean water per head per day...
...pply is available, supply shall be at stand posts, and where the supply is from wells or rive...
...provided. The contractor(s) shall also his/their own cost make arrangements for layin...
...from the existing rains wherever available and shall pay all fees and charges therefor.

...shall be high ground, removed from jungle.

...ctor(s) shall make necessary arrangements for the disposal of excreta from the latrines b...
...o the requirements laid down by the Local Health Authorities. If trenching or incin...
...angements for the removal of the excreta through the *Municipal Committee/author...*
...yed so that arrangements may be made by such Committee/authority for the rem...
...borne by the Contractor and paid direct by him to the Municipality/authority. The cont...
...se of dry system.

...shall provide efficient arrangements for draining away sullage water so as to keep the...

...ecessary arrangements for keeping the camp area sufficiently lighted to avoid accidents t...

...shall make arrangements for conservancy and sanitation in the labour camps according t...
...uthorities.

...of the provisions of section 12 sub-section (1) of the Workmen's Compensation Act, 1923 Gov...
...d by the contractor, in execution of the works, Government will recover from the contra...
...judice to the rights of the Government under section 12, sub-section (2) of the said Act, Gove...
...ereof by deducting it from the security deposit or from any sum due by the Government to the...
...ent shall not be bound to contest any claim made against it under section 12, sub-section (1) o...
...or and upon his giving to Government full security for all cases for which Government might bec...

...against the contractor for the payment of a sum of money arises out of or under the contract, Gover...
...ing, in part of whole, the security deposit of the contractor, and so sell any Government promissory not...
...vent of the security being insufficient or if no security has been taken from the contractor then the...
...deducted from any sum then due or which at any time thereafter may become due from the con...
...sum be not sufficient to cover the full amount recoverable, the contractor shall pay to...

...cause in audit and technical examination of the works and the final bill of the cont...
...yment of the final bill and if as a result of such audit and technical examination an...
...e contractor under the contractor on any work claimed by him to have been do...
...tractor shall be liable to refund the amount of the overpayment and it shall be la...
...in sub-clause (1) of this clause or in any other manner legally permissible; and...
...was paid less than what was due to him under the contract in respect of any...
...id by Government to the contractor.

...d to recover any sum overpaid, nor the contractor shall be ent...
...uperintending Engineer or Executive Engineer on the one...
...fter assessment by the Superintending Engineer of the F...

CC-0. Narinder Safaya Collection. Digitized by eGangotri

...ised, in
...ers should no

...all be maintained in
...washing facilities should

...ned by display on a notice board at a
...be named therein by the contractor
...ations relating to safety precautions, the arrang...
...opened to ... Labour Officer, Engineer-in-charge, of the department of their
...anding the ... clauses from (*i*) to (*xiv*) there is nothing in these to exempt the contract...

by the 4th and 19th every month, to the Engineer-in-charge a true statement showing
...alf of the current month, respectively, (1) the number of labourers employed by him
the accidents that occurred during the said fortnight showing the circumstances unde...
them and (5) the number of female workers who have been allowed Maternity Bene...
...ontractor shall be liable to pay to Government a sum not exceeding Rs. 50 for each
...ve Engineer shall be final in deducting from any bill due to the contractor the amo...

...or indirectly employed in the works for the performance of the contractor's part
...ith all the rules framed by Government from time to time for the protection of h...
...Vorks Department and its contractors.

...*vorkers employed by Contractor.*—Leave and pay during leave shall be regulated
—Maternity leave not exceeding 8 weeks ; 4 weeks upto and including the

...ge.—Up to 8 weeks from the date of miscarriage.
...ve pay during maternity leave will be at the rate of the woman's average d...
the days when full time work was done during a period of three months imme...
that she expects to be confined or at the rate of *seventy five paise a day which*
—Leave pay at the rate of average daily earnings calculated on the total wages
...during a period of 3 months immediately preceding the date of each miscarriage.
OF MATERNITY LEAVE.—No maternity leave benefit shall be admissible to a woman
...an 6 months immediately preceding the date on which she proceeds on leave.

...itting a default or breach of any of the provisions of the Central Public W...
...otection of health and sanitary arrangements for the workers as amended fro...
...ent under the provisions of the above Regulations and Rules which is cha...
...the Government a sum not exceeding Rs. 50/- for every default, breach or fur...
...vent of the contractor(s) defaulting continuously in this respect, the penalty m...
...n of 5 per cent of the estimated cost of the work put to tender. The decision o...

...sufficient number of huts (hereinafter refer...

CC-0. Narinder Safaya Collection. Digitized by eGangotri

CC-0. Narinder Safaya Collection. Digitized by eGangotri